GOVERNMENT OF INDIA
ARCHÆOLOGICAL SURVEY OF INDIA
CENTRAL
ARCHÆOLOGICAL
LIBRARY

ACCESSION NO 23610
CALL No. 091.4912/G.O.M.L.M.

D.G.A. 79

A DESCRIPTIVE CATALOGUE

OF THE

SANSKRIT MANUSCRIPTS

IN THE

GOVERNMENT ORIENTAL MANUSCRIPTS LIBRARY, MADRAS.

3924

BY

M. RANGACHARYA, M.A., RAO BAHADUR,
PROFESSOR OF SANSKRIT AND COMPARATIVE PHILOLOGY, PRESIDENCY COLLEGE;
CURATOR, GOVERNMENT ORIENTAL MSS. LIBRARY; AND
REGISTRAR OF BOOKS, MADRAS.

Prepared under the orders of the Government of Madras.

VOL. XIV.—RELIGION—*continued.*

091.4912
G.O.M.L.M.

MADRAS:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS.

1912.

9/13

[illegible] RY, NEW D[illegible]
23610.
23. 4. 56
Call No. 091.4912/ G.O.M.L.M.

CONTENTS.

CLASS VIII.

RELIGION—(*continued*).

5.—MANTRAS—(*continued*).

23610.
23 4 56
091·4912/G.O.M.L.M.

CONTENTS.

CLASS VIII.

RELIGION—(continued).

5.—MANTRAS—(continued).

5.—MANTRAS—(*continued*).

5.—MANTRAS—(*continued*).

5.—MANTRAS—(*continued*).

5.—MANTRAS—(*continued*).

5.—MANTRAS—(*continued*).

5.—MANTRAS—(*continued*).

5.—MANTRAS—(*continued*).

A DESCRIPTIVE CATALOGUE
OF THE
SANSKRIT MANUSCRIPTS.
VOLUME XIV.

CLASS VIII.—RELIGION—(*continued*).

5. MANTRAS—(*continued*).

No. 7007. राज्यलाभप्रदगोपालमन्त्रः.
RĀJYALĀBHAPRADAGŌPĀLAMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 54*a* of the MS. described under No. 5885

Complete.

This Mantra is in praise of Kṛṣṇa, conceived as the teacher of the Gītā and as the bestower of sovereignty.

Beginning:

अस्य श्रीराज्यलाभप्रदगोपालमन्त्रस्य गीताबोधनगोपालमन्त्रस्य च नारद ऋषिः, अनुष्टुप् छन्दः, गीताबोधनगोपालो देवता; ऐं बीजं, क्लीं शक्तिः, स्वाहा कीलकं, गीताबोधनगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

ऐं क्लीं कृष्णाय नमः ॥

No. 7008. रामकवचम्.
RĀMAKAVACAM

Pages, 3. Lines, 9 on a page.

Begins on fol. 65*a* of the MS. described under No. 21

Complete.

This Kavacamantra is addressed to Rāma. It is believed to have the power to remove one's sins, and to secure protection to one from all kinds of harm and evil.

Beginning:

अस्य श्रीरामकवचस्तोत्रमन्त्रस्य विश्वामित्र ऋषिः, अनुष्टुप् छन्दः, श्रीमत्सीतालक्ष्मणभरतशत्रुघ्नसहितश्रीरामचन्द्रो देवता, मम समस्तपाप-क्षयार्थे समस्तभयनिवारणार्थे जपे विनियोगः । . . . . . .

शिरो मे राघवः पातु फालं दशरथात्मजः ।
कौसलेयो दृशौ पातु विश्वामित्रप्रियः श्रुती ॥

End:

इत्येतानि जपेन्नित्यं मद्भक्तिश्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥

Colophon:

इति श्रीरामकवचस्तोत्रं सम्पूर्णम् ॥

No. 7009. रामकवचम्.
RÂMAKAVACAM.

Pages, 7. Lines, 6 on page.

Begins on fol. 87*a* of the MS. described under No. 2549.

Complete.

Same as the above, except in the beginning which is given below:—

अस्य श्रीरामकवचस्तोत्रमन्त्रस्य विश्वामित्रभगवानृषिः, अनुष्टुप् छन्दः, श्रीरामचन्द्रो देवता; सीतां शक्तिः, मां कीलकं, मम सर्वचोर-व्याघ्र . . . . . भयनिवारणार्थे विनियोगः ।

No. 7010. रामकवचम्.
RÂMAKAVACAM.

Pages, 1. Lines, 5 on a page.

Begins on fol. 17*b* of the MS. described under No. 5938

Complete.

Slightly different from the above in the beginning as given below:—

अस्य श्रीरामकवचस्तोत्रस्य विश्वामित्र ऋषिः, अनुष्टुप् छन्दः, श्रीरामः परमात्मा देवता; सीता भगवती शक्तिः, श्रीरामचन्द्रप्रीत्यर्थे जप विनियोगः ।

No. 7011. रामकवचम्.

RĀMAKAVACAM.

Pages, 4. Lines, 8 on a page.

Begins on fol. 18*a* of the MS. described under No. 5781.

Complete.

Similar to the above

Beginning:

अस्य श्रीरामकवचस्तोत्रमन्त्रस्य बुधकौशिकविश्वामित्र ऋषिः, अनुष्टुप् छन्दः, सीताकल्याणसंयुक्तश्रीरामचन्द्रो देवता; रां बीजं, मन्त्रः कीलकं, श्रीं शक्तिः, मम समस्तव्याघ्रादिक्रूरमृगदुःखशो**कव्याधि**परिहारार्थे श्रीरामचन्द्रप्रीत्यर्थे सकलाभीष्टफलसिद्ध्यर्थे जपे विनियोगः ।

See under number 7008 for the end and colophon.

No. 7012. रामकवचम्.

RĀMAKAVACAM.

Pages, 5. Lines, 6 on a page.

Begins on fol. 86*a* of the MS. described under No. 633.

Complete.

Similar to the above.

Beginning:

अस्य श्रीरामकवचस्तोत्रमन्त्रस्य विश्वामित्रभगवानृषिः, अनुष्टुप् छन्दः, श्रीसीतालक्ष्मणसहितश्रीरामचन्द्रो देवता, श्रीसीतालक्ष्मणसहितश्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

शिरो मे राघवः पातु फालं दशरथात्मजः ।
कौसलेयो दृशौ पातु विश्वामित्रप्रियः श्रुती ॥
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ।

See under the previous number for the end.

Colophon:

श्रीरामकवचं समाप्तम् ॥

No. 7013. रामकवचम्.
RĀMAKAVACAM.

Pages, 3. Lines, 6 on a page.

Begins on fol. 5*a* of the MS. described under No. 757.

Complete, as found in the Hiraṇyagarbhasaṁhitā of the Śrutisārasaṅgraha.

Similar to the above.

Beginning:

अस्य श्रीरामकवचस्तोत्रमन्त्रस्य विश्वामित्र ऋषिः, अनुष्टुप् छन्दः, श्रीरामचन्द्रो देवता; रां बीजं, नमश्शक्तिः, आयेति कीलकं, मम श्रीरामचन्द्रप्रसादसिध्यर्थे जपे विनियोगः ।

शिरो मे राघवः पातु फालं दशरथात्मजः ।
कौसलेयो दृशौ पातु विश्वामित्रप्रियश्श्रुती ॥

See under the previous number for the end.

Colophon:

इति श्रुतिसारसङ्ग्रहे परमरहस्ये हिरण्यगर्भसंहितायां श्रीरामकवचस्तोत्रं सम्पूर्णम् ॥

No. 7014. रामकवचम्.
RĀMAKAVACAM.

Pages, 2. Lines, 6 on a page.

Begins on fol. 7*a* of the MS. described under No. 6231.

Incomplete.

Similar to the above.

Beginning:

अस्य श्रीरामकवचस्तोत्रमहामन्त्रस्य विश्वामित्रो भगवानृषिः, अनुष्टुप् छन्दः, श्रीरामचन्द्रपरमात्मा वासुदेवो देवता; रां बीजं, सीता इति शक्तिः, लक्ष्मण इति कीलकं, श्रीरामचन्द्रप्रसादसिध्यर्थे जपे विनियोगः ।

End:

इन्दीवरश्यामलमायताक्षं धनुर्धरं नीलजटावजूटम् ।
पार्श्वद्वये लक्ष्मणमैथिलीभ्यां निषेव्यमाणं प्रणतोऽस्मि रामम् ॥

No. **7015.** रामकवचम्.

RĀMAKAVACAM.

Substance, palm-leaf. Size, 11⅓ × 1⅓ inches. Pages, 7. Lines, 5 on a page. Character, Grantha. Condition, injured. Appearance, old.

Begins on fol. 26*b*. The other works herein are Saumyajāmātṛpūrvadinacaryā 1*a*, Yatirājaviṁśati 4*a*, Saumyajāmātṛmunyuttaradinacaryā 10*a*, Prārthanāpañcaka 14*a*, Śrīguṇaratnakōśa 15*a*, Ślōkadvaya 29*a*, Ślōkatraya 30*a*, Catuśślōkī 30*b*.

Complete.

Similar to the above.

Beginning :

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामकुटमण्डितम् ॥
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्रातुमाविर्भूतमजं विभुम् ॥

The remaining portion is the same as in the work described under No. 7008.

No. **7016.** रामकवचम्.

RĀMAKAVACAM.

Substance, palm-leaf. Size, 14¼ × 1⅓ inches. Pages, 6. Lines, 6 on a page. Character, Grantha. Condition, much injured. Appearance, new.

Begins on fol. 12*b*. The other works herein are Saumyajāmātṛyōgidinacaryā (Pūrvā) 1*a*, Yatirājaviṁśati 6*a*, Saumyajāmātṛyōgidinacaryā (Uttarā) 8*b*, Prārthanāpañcaka 10*b*, Śrīstava 11*a*, Ślōkadvaya 15*a*, Catuśślōkī 15*b*, Śrīguṇaratnakōśa 16*a*, Kṣamāṣōḍaśī 27*a*.

Complete.

Same as the above.

No. 7017. रामकवचम्.
RĀMAKAVACAM.

Pages, 3. Lines, 6 on a page.

Begins on fol. 46*a* of the MS. described under No. 5858.

Complete, as found in the Viṣṇupurāṇa.

Similar to the above.

Beginning:

अस्य श्रीरामकवचस्तोत्रमन्त्रस्य बुद्धकौशिक ऋषिः, अनुष्टुप् छन्दः, सीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरामचन्द्रो देवता; रां बीजं, श्रीं शक्तिः, ह्रीं कीलकं, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

* * * *

ओं नमो भगवते रक्षोघ्नाय रघुनन्दनाय गुरवे सुप्रसन्नाय प्रणतार्तिहरायापरिमिततेजसे श्रीरामाय स्वाहा ।

End:

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥

Colophon:

इति श्रीविष्णुपुराणे रामचन्द्रकवचं सम्पूर्णम् ॥

No. 7018. रामकवचम्.
RĀMAKAVACAM.

Pages, 3. Lines, 10 on a page.

Begins on fol. 8*a* of the MS. described under No. 6090.

Complete.

Same as the above.

No 7019. रामकवचम्.
RĀMAKAVACAM.

Pages, 8. Lines, 5 on a page.

Begins on fol. 68*a* of the MS. described under No. 5953.

Complete, as found in the Pādmapurāṇa.

Similar to the above.

Beginning:

अस्य श्रीरामकवचस्तोत्रमन्त्रस्य वेदव्यासभगवान् ऋषिः, अनुष्टुप् छन्दः, श्रीरामचन्द्रो देवता, श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ।

End:

सन्नद्धकवची खड्गी चापबाणधरो युवा ।
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥
श्रीरामः पातु सलक्ष्मण ओन्नम इति ॥

Colophon:

इति पाद्मपुराणे श्रीरामकवचं सम्पूर्णम् ॥

No. **7020.** रामकवचम्.
RĀMAKAVACAM.

Pages, 5. Lines, 5 on a page.

Begins on fol. 13*a* of the MS. described under No. 831.

Complete.

Same as the above.

No. **7021.** रामकवचम्.
RĀMAKAVACAM.

Pages, 8. Lines, 5 on a page.

Begins on fol. 15*a* of the MS. described under No. 2040.

Complete.

Similar to the above.

Beginning:

अस्य श्रीरामकवचस्तोत्रमन्त्रस्य विश्वामित्रभगवानृषिः, अनुष्टुप् छन्दः, श्रीरामचन्द्रो देवता; श्रीराम इति बीजं, लक्ष्मणाग्रज इति शक्तिः, सीतावल्लभ इति कीलकं, मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।

See under No 7019 for the end.

Colophon:

रामकवचं सम्पूर्णम् ॥

No. **7022.** रामकवचम्.
RĀMAKAVACAM.

Pages, 3. Lines, 6 on a page.
Begins on fol. 7*b* of the MS. described under No. 6231.
Complete.
Similar to the above.

Beginning:

अस्य श्रीरामकवचस्तोत्रमहामन्त्रस्य विश्वामित्रभगवानृषिः, अनुष्टुप् छन्दः, रामचन्द्रपरमात्मा वासुदेवो देवता; सीता इति शक्तिः, लक्ष्मण इति बीजं, रामचन्द्र इति कीलकं, रामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

See under No. 7019 for the end.

No. **7023.** रामकवचम्.
RĀMAKAVACAM.

Pages, 2. Lines, 8 on a page.
Begins on fol. 45*a* of the MS. described under No. 369.
Complete.
Similar to the above.

Beginning:

शिरो मे राघवः पातु फालं दशरथात्मजः ।
कौसलेयो दृशौ पातु विश्वामित्रप्रियश्शुचिः(ती) ॥
घ्राणं पातु मखत्राणः मुखं सौमित्रिवत्सलः ।
दन्तान् दाशरथिः पातु तालु सालप्रभेदनः ॥

End:

जगज्जैत्रैकमन्त्रेण रामनामाभिरक्षितम् ।
यः करे धारयेत् सर्वे करस्थास्सर्वसिद्धयः ॥
वज्रपञ्जरनामैतत् यो रामकवचं पठेत् ।
अव्याहताज्ञस्सर्वत्र लभते जयमङ्गलम् ॥

No. 7024. रामकवचवज्रपञ्जरम्.

RĀMAKAVACAVAJRAPAÑJARAM.

Pages, 5. Lines, 4 on a page.

Begins on fol. 74*a* of the MS. described under No. 757.

Complete.

The repetition of this Mantra is believed to please Rāma and to secure safety and protection to one from thieves, cruel animals, evil spirits, etc., as if one were inside an adamantine enclosure.

Begnining:

अगस्त्य उवाच—

श्रृणु वक्ष्याम्यहं सौम्य सुतीक्ष्ण मुनिसत्तम ।
अद्वैतानन्यचैतन्यशुद्धसत्त्वैकलक्षणम् ॥

बहिरन्तस्सुतीक्ष्णास्मिन् रामचन्द्रः प्रकाशते ।
तत्त्वविद्योगिनो नित्यं रमन्ते चित्सुखात्मनि ॥

इति रामपदेनासौ परब्रह्माभिधीयते ।

* * * *

अस्य श्रीरामकवचस्तोत्रमन्त्रस्य अगस्त्यभगवानृषिः, श्रीं बीजं, सीता शक्तिः, मां कीलकं, सर्वचोरव्याघ्रयक्षगन्धर्वभूतप्रेतपिशाचकृत्रिम-रोगज्वरप्रलयनिर्हरणार्थे श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

* * * *

श्रीरामः पातु मे मूर्ध्नि पूर्वस्मिन् रघुवंशजः ।
दक्षिणे मे रघुवरः पश्चिमे पातु राघवः ॥

End:

यः करे धारयेत्तस्य कवचं वज्रपञ्जरम् ।
आयुरारोग्यमैश्वर्यं लभेत्तत्र न संशयः ॥

सत्यव्रतौ रघुवरौ विमलौ बलाढ्यौ दैत्यान्तकौ सुरवरौ सुगुणौ महेशौ ।
. . . . विप्रप्रियौ नृपवरौ मनसा स्मरामि ॥

No. 7025. रामकीलकम्.

RĀMAKĪLAKAM.

Page, 1. Lines, 7 on a page.

Begins on fol. 18*a* of the MS. described under No. 757.

Complete, as found in Agastyasaṁhitā.

This Mantra is in praise of Rāma. It is said to be as efficacious as the six-syllabled Rāma-Mantra, and is intended to be repeated prior to the commencement of the repetition of the Rāmamantra. This is called Rāmakīlaka as it is believed to have the power to enable one to fix Rāma in one's mind as if with the aid of a peg.

Beginning:

अगस्त्य उवाच—

मन्त्ररूपं प्रवक्ष्यामि शृणु नारद तत्परः ।
अनलादिमकारान्तं मन्त्रं षड्वर्णसंयुतम् ॥
षडक्षरात्मकं मन्त्रं तारकं ब्रह्मसंज्ञितम् ।
राजेन्द्रं राघवं रामं राजानं रघुनन्दनम् ॥
राजीवलोचनं वन्दे राक्षसारिं रघूत्तमम् ।
रामभद्रं रघुवरं राजेशं रघुवल्लभम् ॥

End:

महादेवाय महते महेशाय महात्मने ।
मन्त्ररूपाय रामाय महतां पतये नमः ॥
इति श्रीरामचन्द्रस्य मन्त्रराजात्मकं स्तवम् ।

* * * *

एवं स्तुत्वा जपेन्मन्त्रं षट्सहस्रं दिने दिने ।
अष्टोत्तरसहस्रं वा यथाशक्त्यनुसारतः ॥

Colophon:

इत्यगस्त्यसंहितायां रामकीलकं समाप्तम् ॥

No. **7026.** रामखड्गस्तोत्रमन्त्रः.

RĀMAKHADGASTŌTRAMANTRAḤ.

Pages, 5. Lines, 7 on a page.

Begins on fol. 71*b* of the MS. described under No. 235.

Complete.

The repetition of this Mantra is intended to please Rāma. It is also believed to be efficacious in removing the fear of harm from evil spirits, the fear of an inundation by water, and the fear of being put into enchained bondage, etc.

Beginning:

अस्य श्रीरामखड्गस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता; रां बीजं, रीं शक्तिः, रूं कीलकं, मम श्रीरामचन्द्रप्रसादसिद्ध्यर्थे . . . . . गणपतिभयोदकभयबन्धनादिभयनिवारणार्थे जपे विनियोगः ।

End:

ओं ह्रीं श्रीं क्लीं हुं ओं खें खें क्षें क्षें फट् स्वाहा । श्रीरामचन्द्राय गरुडवाहनाय गजेन्द्रवरदाय श्रीरामचन्द्राय नमोऽस्तु नमोऽस्तु । ओं ह्रीं श्रीं क्लीं ओं यं ओं ह्रीं फट् स्वाहा ॥

No. 7027. रामगायत्री.

RĀMAGĀYATRĪ.

Page, 1. Lines, 11 on a page.

Begins on fol. 7*b* of the MS. described under No. 6090.

Complete.

This Mantra is in the form of the Gāyatrī-Mantra both in regard to its metre and in regard to the manner of contemplating the presiding diety, which manner consists in praying for inspiration to have thoughts about the deity contemplated. The word, Gāyatrī, implies that it protects the person who repeats that Mantra.

Beginning and **End**:

रामगायत्री —

दाशरथाय विद्महे सीतावल्लभाय धीमहि । तन्नो रामः प्रचोदयात् ॥

No. 7028. रामगायत्री.
RĀMAGĀYATRĪ.

Page, 1. Lines, 10 on a page.

Begins on fol. 95*a* of the MS. described under No. 5566, wherein this has been omitted to be included in the list of other works given therein.

Complete.

Same as the above.

No. 7029. रामगायत्री.
RĀMAGĀYATRĪ.

Page, 1. Lines, 6 on a page.

Begins on fol. 45*b* of the MS. described under No. 5858.

Complete.

Same as the above.

No. 7030. रामगायत्री.
RĀMAGĀYATRĪ.

Page, 1. Lines, 28 on a page.

Begins on fol. 214*b* of the MS. described under No. 581, wherein it is found to be in the Mantramālikā group given as other work therein.

Complete.

Same as the above.

No. 7031. रामचन्द्राष्टाक्षरीमन्त्रः.
RĀMACANDRĀṢṬĀKṢARĪMANTRAḤ.

Page, 1. Lines, 11 on a page.

Begins on fol. 6*a* of the MS. described under No. 6090.

Complete.

This Mantra which consists of eight syllables is considered to have the power of safe-guarding one through Rāma's favour from the evils that may come from various quarters.

Beginning:

अस्य श्रीरामचन्द्राष्टाक्षरीमहामन्त्रस्य वसिष्ठः ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता; रामो बीजं, जानकी शक्तिः, हनूमान् कीलकं, श्रीहनुमत्सीतालक्ष्मणभरतशत्रुघ्नपरिवारसमेतश्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

पूर्वपश्चिमदक्षिणोत्तराकाशपातालादिसर्वदिशं बन्धय बन्धय यं रं लं वं शं षं सं हं ळं क्षं सर्वभूतयक्षराक्षसान् नाशय नाशय वं वटुकाय भूर्भुवस्सुवरोमिति दिग्बन्धः । मनुः—ओं श्रीं रां रामाय नमः॥

No. 7032. रामचन्द्राष्टाक्षरीमन्त्रः.
RĀMACANDRĀṢṬĀKṢARĪMANTRAḤ.

Pages, 2. Lines, 21 on a page.

Begins on fol. 19*b* of the MS. described under No. 2373.

Complete.

Same as the above.

No. 7033. रामचन्द्राष्टाक्षरीमन्त्रः.
RĀMACANDRĀṢṬĀKṢARĪMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol 44*a* of the MS. described under No. 5858.

Complete.

Same as the above.

No. 7034. रामतारकमन्त्रः.
RĀMATĀRAKAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 21*a* of the MS. described under No. 6090.

Incomplete.

The repetition of this Mantra is intended to enable one to obtain freedom from the bondage of Saṁsāra.

Beginning :

अस्य श्रीरामतारकमहामन्त्रस्य ब्रह्मा ऋषिः शिरसि, गायत्री छन्दः मुखे, सीतारामचन्द्रो देवता हृदये, रां बीजं नाभौ, रीं शक्तिः गुह्ये, स्वाहा इति कीलकं पादयोः, मम श्रीसीतारामचन्द्रप्रसादसिध्यर्थे जपे विनियोगः ।

End :

अथ मनुः—

सीता रां रामाय नमः । पुनः न्यासध्यानपञ्चपूजां कुर्यात् ॥

हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति भूमित-
[(जेद) ले ।

यदि मु(नह्य)ति मु(नह्य)ति वामकरे यदि (परि)नश्यति नश्यति
[शत्रुकुले(लम्) ॥

. . . . परिमुञ्चति मुञ्चति शृङ्खलिकाम् ।

No. 7035. रामतारकषडक्षरीब्रह्मविद्यामहामन्त्रः.
RĀMATĀRAKAṢAḌAKṢARĪBRAHMAVIDYĀMAHĀ-
MANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 1*a* of the MS. described under No. 5864, wherein it is given as Rāmabrahmavidyāṣaḍakṣarīmantra in the list of other works given therein.

Complete.

Similar to the above.

This Mantra consists of six syllables.

Beginning :

अस्य श्रीरामतारकषडक्षरीब्रह्मविद्यामहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रः परमात्मा देवता ; रां बीजं दक्षिणस्तने, नमश्शक्तिः वामस्तने, रामायेति कीलकं हृदि, श्रीरामचन्द्रप्रसादसिध्यर्थे जपे विनियोगः ।

End:

गुरुदेवतात्मैक्यं विभावयन् दिनेदिने षट्सहस्रं त्रिसहस्रं सहस्रं त्रिशतं शतमेव वा मूलमन्त्रं मौनेन जपेत् । मनुः रां रामाय नमः ॥

No. **7036.** रामतारकषडक्षरीमन्त्रः.

RĀMATĀRAKAṢAḌAKṢARĪMANTRAḤ.

Pages, 2. Lines, 19 on a page.

Begins on fol. 9*b* of the MS. described under No. 2886.

Complete.

Similar to the above.

Beginning:

अस्य श्रीरामतारकषडक्षरीमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीरामो देवता ; रां बीजं, रीं शक्तिः, रूं कीलकं, सीतारामप्रीत्यर्थे जपे विनियोगः ।

End:

पूर्ववद्ग्रथितश्चान्यत् तस्याद्यं त्रिः प्रकल्पयेत् ।
विदर्भग्रथितं नाम मन्त्रलक्षणमुत्तमम् ॥
सर्वकर्मकरं प्रोक्तं सर्वैश्वर्यफलप्रदम् ।
एवमेते प्रयोगाः स्युः सिद्धमन्त्रस्य सिद्धिदाः ॥

No. **7037.** रामदशाक्षरीमन्त्रः.

RĀMADAŚĀKṢARĪMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 287*b* of MS. described under No. 5477, wherein it is found to be in the Mantramālikā in the list of other works given therein.

Complete.

This Mantra consists of ten syllables and is believed to be efficacious in the accomplishment of one's desires.

Beginning :

अस्य श्रीराम(दशाक्षरी)मन्त्रस्य अगस्त्य ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता; रं बीजं, ह्रीं शक्तिः, मम इष्टार्थसिद्ध्यर्थे विनियोगः ।

End :

मन्त्रः—

ओं ह्रीं (श्रीं क्लीं) रं रामाय नमः ॥

Colophon :

इति रामदशाक्षरी ॥

No. 7038. रामदशाक्षरीमन्त्रः.

RĀMADAŚĀKṢARĪMANTRAḤ.

Page, 1. Lines, 28 on a page.

Begins on fol. 244*a* of the MS. described under No. 581, wherein it is found to be in the Mantramālika group given as other work therein.

Complete.

Similar to the above.

Beginning :

अस्य श्रीराम(दशाक्षरी)मन्त्रस्य अगस्त्य ऋषिः, गायत्री छन्दः, श्रीरामो देवता; ओं बीजं, ह्रीं शक्तिः, ममेष्टकाम्यार्थसिद्ध्यर्थे विनियोगः ।

End :

मन्त्रः—

ओं ह्रीं श्रीं (क्लीं रं) रामाय नमः ॥

No 7039. रामदशाक्षरीमन्त्रः.

RĀMADAŚĀKṢARĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 91*b* of the MS. described under No. 5566.

Complete.

Same as the above.

No. 7040. रामदशाक्षरीमन्त्रः.
RĀMADAŚĀKṢARĪMANTRAḤ.

Page, 1. Lines, 28 on a page.

Begins on fol. 241a of the MS. described under No. 581, wherein it is found in the Mantramālikā group given as other work therein.

Complete.

Similar to the above.

Beginning and **End**:

हुं जानकीवल्लभाय स्वाहा —इति दशाक्षरी ॥

No. 7041. रामदुर्गकवचः.
RĀMADURGAKAVACAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 99a of the MS. described under No. 2549.

Complete.

The repetition of this Mantra which is addressed to Rāma is to secure protection for one from all dangers, as if one were protected by an impenetrable armour. It is believed to be also efficacious in wiping off one's sins and in securing salvation.

Beginning:

अस्य श्रीरामदुर्गकवचस्तोत्रमहामन्त्रस्य विश्वामित्र ऋषिः, अनुष्टुप् छन्दः, सीतारामचन्द्रो देवता; रां बीजं, नं शक्तिः, मः कीलकं, सीतारामचन्द्रप्रसादासिद्ध्यर्थे जपे विनियोगः ।

* * * *

श्रीरामो रक्षतु प्राच्यां रक्षेद्याम्यां च लक्ष्मणः ।
प्रतीच्यां भरतो रक्षेदुदीच्यां शत्रुसूदनः ॥
ईशान्यां जानकी रक्षेदाग्नेय्यां सूर्यनन्दनः ।

End:

रामदुर्गं पठेद्भक्त्या सर्वोपद्रवनाशनम् ।

सर्वपापक्षयं नृणां स गच्छेद्वैष्णवं पदम् ॥
अक्षय्यबाणतूणीरसमारोपितकार्मुकः ।
करे विराजितशरः श्रीरामश्शरणं मम ॥

No. 7042. रामदुर्गम्.
RĀMADURGAM.

Pages, 2. Lines, 5 on a page.

Begins on fol. 15*a* of the MS. described under No. 757.

Complete.

The authorship of this Mantra is attributed to Viśvāmitra

Similar to the above.

Beginning:

विश्वामित्र उवाच—

श्रीरामो रक्षतु प्राच्यां याम्यां चैव स लक्ष्मणः ।
प्रतीच्यां भरतो रक्षेदुदीच्यां शत्रुसूदनः ॥
ईशान्यां जानकी रक्षेदाग्नेय्यां सूर्यनन्दनः ॥
विभीषणश्च नैरृत्यां वायव्यां वायुनन्दनः ॥
ऊर्ध्वं रक्षेन्महाविष्णुर्मध्यं रक्षेन्नृकेसरी ।
श्रीरामाख्यं महादुर्गं विश्वामित्रकृतं शुभम् ॥
यः पठेद्भयकाले तु भयं तस्य विनश्यति ।
रामदुर्गं पठेद्भक्त्या सर्वोपद्रवनाशनम् ॥

End:

श्रीराम शत्रुसङ्घान् वै जहि मर्दय घातय ।
भूतप्रेतपिशाचादीन् श्रीराम नु विनाशय ॥

Colophon:

इति विश्वामित्रविरचितंरामदुर्गं संपूर्णम् ॥

No. 7043. रामदुर्गम्.
RĀMADURGAM.

Page, 1. Lines, 6 on a page.

Begins on fol. 88*b* of the MS. described under No. 673.

Complete.

Similar to the above.

See under the previous number for the beginning.

End:

रामदुर्गं पठेन्नित्यं सर्वोपद्रवनाशनम् ।
सर्वशत्रुहरं नृणां स गच्छेद्वैष्णवं पदम् ॥

No. 7044. रामदुर्गम्.
RĀMADURGAM.

Page, 1. Lines, 5 on a page.

Begins on fol. 16*a* of the MS. described under No. 5938.

Complete.

Similar to the above.

See under the previous number for the beginning.

End:

यः पठेद्भयकाले तु सर्वशत्रुविनाशनम् ।
सर्वसम्पत्प्रदं नृणां विष्णुलोकं च शाश्वतम् ॥

Colophon:

श्रीरामदुर्गं सम्पूर्णम् ॥

No 7045. रामद्वादशाक्षरीमन्त्रः.
RĀMADVĀDAŚĀKṢARĪMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 287*b* of the MS. described under No. 5477.

Complete.

This Mantra consists of 12 syllables, and is addressed to Rāma; its repetition is believed to enable one to accomplish one's desires.

Beginning:

अस्य श्रीरामद्वादशाक्षरीमन्त्रस्य अगस्त्य ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता; रं बीजं, श्रीं शक्तिः, ममेष्टकाम्यार्थसिद्ध्यर्थे विनियोगः ।

End:

मन्त्रः—

ओं ह्रीं भरताग्रज राम क्लीं स्वाहा । पूर्ववज्जपहोमः ॥

Colophon:

इति रामद्वादशाक्षरी ॥

No. **7046**. रामद्वादशाक्षरीमन्त्रः.

RĀMADVĀDAŚĀKṢARĪMANTRAḤ.

Page, 1. Lines, 28 on a page.

Begins on fol. 244*a* of the MS. described under No. 5ɛ1, wherein it is found to be in the Mantramālikā group given in the list of other works therein.

Incomplete.

Similar to the above.

Beginning:

अस्य श्री(राम)द्वादशाक्षरमन्त्रस्य अगस्त्य ऋषिः, गायत्रीछन्दः, श्रीरामो देवता, रं बीजं, श्रीं शक्तिः, ममेष्टकाम्यार्थसिद्ध्यर्थे विनियोगः ।

End:

ध्यानार्चनादि पूर्ववत् । मन्त्रः——ओं ह्रीं (भरताग्रज राम क्लीं स्वाहा) ॥

No. **7047**. रामद्वादशाक्षरीमन्त्रः.

RĀMADVĀDAŚĀKṢARĪMANTRAḤ.

Pages, 2. Lines, 16 on a page

Begins on fol. 94*b* of the MS. described under No. 5566.

Complete.

Same as the above.

No. 7048. राममन्त्रः.
RĀMAMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 12*b* of the MS. described under No. 5786.

Complete.

The due repetition of this Mantra is believed to secure the grace of Rāma.

Beginning:

रां रामाय नमः इति प्राणायामः १२. . . . . . .

अस्य श्रीराममहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामो देवता; श्रीरामप्रेरणया रामप्रीत्यर्थे जपे विनियोगः ।

End:

ओं रां रामाय नमः ओं—इति जपः । उपसंहारः पूर्ववत् ॥

No. 7049. राममन्त्रः.
RĀMAMANTRAḤ.

Pages, 3. Lines, 18 on a page.

Begins on fol. 286*b* of the MS. described under No. 5477.

Complete.

Similar to the above.

Beginning:

अस्य श्रीराममन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता; रं बीजं, नमश्शक्तिः, श्रीरामचन्द्रप्रसादसिद्ध्यर्थे विनियोगः ।

End:

मन्त्रः —

रं रामाय नमः । पुनश्चरणमक्षरलक्षं दशांशं तर्पणहोमः ॥

No. 7050. राममन्त्रः.
RĀMAMANTRAḤ.

Pages, 2. Lines, 28 on a page.

Begins on fol. 243*b* of the MS described under No. 581, wherein it is found to be in the Mantramālikā group.

Complete.

Different from the above only in the end which is given below :—

इति मूलमन्त्रः । पुरश्चरणं ६ लक्षम् । बिल्वफलपत्रपुष्प(ष्पेण)घृत- मधुशर्कराप्लुतेन दशांशहोमः ॥

No. 7051. राममन्त्रः.
RĀMAMANTRAḤ.

Pages, 2. Lines, 10 on a page.

Begins on fol. 94*b* of the MS described under No. 5566.

Complete.

Same as the above

No. 7052. राममन्त्रकवचः.
RĀMAMANTRAKAVACAḤ.

Pages, 4. Lines, 6 on page.

Begins on fol. 16*a* of the MS. described under No. 757.

Complete, as found in the Brahmayāmala.

The repetition of this Kavacamantra is believed to be a necessary preliminary to the repetition of the Rāmamantra.

Beginning:

पार्वत्युवाच—

भगवन् सर्वदेवेश सर्वदेवनमस्कृत ।
सर्वं मे कथितं देव राममन्त्रं विशेषतः ॥
त्रैलोक्यमोहनं रामकवचं मम सूचितम् ।
कथयस्व महादेव यद्यहं तव वल्लभा ॥

* * * *

अस्य श्रीराममन्त्रकवचमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता, मम चतुर्वर्गसाधने विनियोगः ।

प्रणवो मे शिरः पातु तारकब्रह्मरूपधृत् ।
अनन्ताग्निसहस्रेन्दुर्नासामेकाक्षरोऽवतु ॥

रां रामाय नम इति षड्वर्णो भुक्तिमुक्तिदः ।
फालं पायान्नेत्रयुग्मं रामो व्यक्षरसंज्ञितः ॥

End:

अष्टोत्तरशतं जप्त्वा दशांशं होममाचरेत् ।
ततस्स्तुत्वा तु कवचं सर्वकार्याणि साधयेत् ॥
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्यां विना हि सा ।

* * * *

इदं कवचमज्ञात्वा पूजयेत्(प्रजपे)द्राममन्त्रकम् ॥
शतलक्षं प्रजप्तोऽपि न मन्त्रसिद्धिदायकः ।
स शस्त्रघातमाप्नोति शोचतां मृतिमाप्नुयात् ॥
सम्यग्ज्ञात्वा तु कवचं मन्त्रस्स्याच्छीघ्रसिद्धिदः ।
तस्मात् स्तोत्रं जपेन्नित्यं सर्वसिद्धिफलप्रदम् ॥

Colophon:

इति श्रीब्रह्मयामले पार्वतीश्वरसंवादे रामस्य त्रैलोक्यमोहनं नाम कवचं संपूर्णम् ॥

No. 7053. राममालामन्त्रः.
RĀMAMĀLĀMANTRAḤ.

Pages, 3. Lines, 12 on a page.

Begins on fol. 6*a* of the MS. described under No. 6090.

Complete.

This Mantra is in praise of Rāma under various significant names. Its repetition is considered to have the power of destroying evil spirits and also one's enemies.

Beginning:

ओं नमो भगवते श्रीरामचन्द्राय अपरिमिततेजसे वीरबलमहापराक्रमाय रणोग्रभयङ्कराय हरचापखण्डनाय कोदण्डदीक्षागुरवे परशुरामगर्वापहरणाय विश्वामित्रयागसंरक्षणाय ताटकाप्राणनाशनाय अहल्याशापविमोचनाय ।

End:

ऐं सर्वविद्याय क्लीं जगत्रयवशीकरणाय सौः सर्वजनमनस्संक्षोभनाशायं श्रीं महासंपत्प्रदाय ग्लौं भूमण्डलाधिपतये द्रां चिरञ्जीविने श्रीरामाय सर्वभूतप्रेतपिशाचराक्षसदानवमर्दनरामाय रां रीं रूं रैं रौं रः मम सकलशत्रून्संहर श्रीबडबानलरामाय अघोररूपाय हुं फट् स्वाहा॥

द्वादशकृत्वः जपेत्॥

No. **7054.** राममालामन्त्रः.

RĀMAMĀLĀMANTRAḤ.

Pages, 2. Lines, 21 on a page.

Bgins on fol. 20*a* of the MS. described under No. 2373, wherein this has been omitted to be included in the list of the works contained therein.

Complete.

Same as the above.

No. **7055.** राममालामन्त्रः.

RĀMAMĀLĀMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 44*a* of the MS. described under No. 5858.

Complete.

Same as the above.

No. **7056.** राममालामन्त्रः.

RĀMAMALĀMANTRAḤ.

Page, 1. Lines, 11 on a page.

Begins on fol. 7*b* of the MS. described under **No. 6090,** wherein this has been omitted to be included in the list of other works contained therein.

Complete.

Similar to the above.

Beginning and **End:**

ओं नमो भगवते रघुनन्दनाय रक्षोघ्नविश(शार)दाय मधुरप्रसन्नवदनाय अमिततेजसे बलाय रामाय विष्णवे नमः॥

No. **7057.** राममालामन्त्रः.
RĀMAMĀLĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 45*b* of the MS. described under No. **5858,** wherein this has been omitted to be included in the list of other works given therein.

Complete.

Same as the above.

No. **7058.** राममालामन्त्रः.
RĀMAMĀLĀMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 287*b* of the MS. described under No **5477,** wherein this is found in the Mantramālikā 273*a* given in the list of other works contained therein.

Complete.

Same as the above.

No. **7059.** राममालामन्त्रः.
RĀMAMĀLĀMANTRAḤ.

Page, 1. Lines, 28 on a page.

Begins on fol. 244*a* of the MS. described under No. **581,** wherein this is found in the Mantramālikā 229*a* given in the list of other works contained therein.

Complete.

Same as the above.

No. **7060.** राममालामन्त्रः.
RĀMAMĀLĀMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 94*b* of the MS. described under No. **5566.**

Complete.

Same as the above.

No 7061. राममालामन्त्रः.

RĀMAMĀLĀMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 17*b* of the MS. described under No. 5864, wherein this has been omitted to be included among the other works contained therein.

Complete.

Same as the above.

Colophon :

अयं मालामन्त्रः ॥

No. 7062. राममालामन्त्रः.

RĀMAMĀLĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 17*b* of the MS. described under No. 757.

Complete.

Same as the above with the difference that Rāmadaśākṣarī-mantra is added on at the end.

No 7063. राममालामन्त्रः.

RĀMAMĀLĀMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 17*b* of the MS described under No. 5864.

Complete.

Similar to the above.

Beginning :

अस्य श्रीराममालामन्त्रस्य वसिष्ठ ऋषिः, अनुष्टुप् छन्दः, श्रीराममालामन्त्रो देवता; रां बीजं, रीं शक्तिः, रूं कीलकं, मम श्रीरामचन्द्रमालामन्त्रदेवताप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

ओं मां मीं मूं मैं मौं मः, ओं रां रीं रूं रैं रौं रः, ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः, ग्रां ग्रीं ग्रूं ग्रैं ग्रौं ग्रः, ओं ळां ळीं ळूं ळैं ळौं ळः, ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः हुं फट् स्वाहा ॥

No. 7064. रामवज्रकवचम्.
RĀMAVAJRAKAVACAM.

Pages, 4. Lines, 5 on a page.

Begins on fol. 1*b* of the MS. described under No. 5864

Complete.

The repetition of this Mantra relating to Rāma is believed to confer on one long life, health and prosperity.

Beginning:

अस्य श्रीरामवज्रकवचमन्त्रस्य अगस्त्य ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता; रां बीजं, नमश्शक्तिः, आयेति कीलकं, श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

*   *   *   *

श्रीरामः पातु मे मूर्ध्नि तत्पूर्वे रघुवंशजः ।
. . . . . रघुपतिः फालं दशरथात्मजः ॥

भ्रुवौ दूर्वादलश्यामः तयोर्मध्यं जनार्दनः ।
श्रोत्रे मे पातु राजेन्द्रो दृशौ राजीवलोचनः ॥

End:

इतीदं रामचन्द्रस्य कवचं वज्रनामकम् ।
गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः ।

*   *   *   *

यः पठेद्धारयेन्नित्यं कवचं वज्रसंज्ञिकम् ।
आयुरारोग्यमैश्वर्यं लभते नाम संशयः ॥

Colophon:

इति श्रीरामवज्रकवचं संपूर्णम् ॥

No. 7065. रामषडक्षरीतारकब्रह्ममहामन्त्रः.

RĀMAṢAḌAKṢARĪTĀRAKABRAHMAMAHĀMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 48*a* of the MS. described under No. 235.

Complete.

This Mantra consisting of six syllables is addressed to Rāma. It is called Tārakabrahmamahāmantra, because its repetition is believed to be capable of enabling one to obtain salvation.

Beginning :

ततः द्विराचम्य मूलमन्त्रेण प्राणायामत्रयं कृत्वा पूरकं १२, कुम्भकं १६, रेचकं १०. सङ्कल्पः—मम उपात्तसमस्तदुरितक्षयद्वारा श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरामचन्द्रमुद्दिश्य श्रीरामचन्द्रप्रीत्यर्थं श्रीरामचन्द्रषडक्षरीतारकब्रह्ममहामन्त्रजपं करिष्ये ।

अस्य श्रीरामषडक्षरीतारकब्रह्ममहामन्त्रस्य ब्रह्मा ऋषिः शिरसि, गायत्री छन्दः मुखे, जिह्वाग्रे श्रीरामचन्द्रो देवता ।

End :

मनुः—

क्लीं रामाय नमः, ओं क्लीं रामाय नमः मूलं षट्सहस्रम् । (लं) पृथिव्यात्मने गन्धतन्मात्रप्रकृत्यानन्दात्मने श्रीरामचन्द्राय गन्धमुद्रया दिव्यश्रीगन्धं कल्पयामि, हं आकाशात्मने शब्दतन्मात्रप्रकृत्यानन्दात्मने श्रीरामचन्द्राय पुष्पमुद्रया नानाविधपुष्पाणि कल्पयामि, वौषट् यं वायव्यात्मने स्पर्शतन्मात्रप्रकृत्यानन्दात्मने श्रीधूपमुद्रया दिव्यश्रीधूपं कल्पयामि, रं वह्न्यात्मने रूपतन्मात्रप्रकृत्यानन्दात्मने श्रीरामचन्द्राय दीपमुद्रया सहस्रनीराजनं समर्पयामि ॥

No. 7066. रामषडक्षरीमन्त्रः.

RĀMAṢAḌAKṢARĪMANTRAḤ.

Page, 1. Lines, 11 on a page.

Begins on fol. 7*b* of the MS. described under No. 6098.

Complete.

This Mantra also consists of six syllables. Its repetition is held to be able to secure the grace of Rāma. The Mantra-formula here is the same as in Rāmatārakaṣaḍakṣarībrahmavidyāmahāmantra : *vide* No. 7035.

Beginning :

अस्य श्रीरामषडक्षरीमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामो देवता ; रां बीजं, नमश्शक्तिः, आयेति कीलकं, श्रीरामप्रसाद-सिद्ध्यर्थे जपे विनियोगः ।

End :

शङ्खं चक्रं गदापद्मं धेनुकौस्तुभगारुडाः ।
श्रीवत्सवनमाले च नव मुद्राश्च दर्शयेत् ॥

मनुः—रां रामाय नमः ॥

No. **7067.** रामषडक्षरीमन्त्रः.
RĀMAṢAḌAKṢARĪMANTRAḤ.

Page, 1. Lines, 7 on a page.
Begins on fol. 71*a* of the MS. described under No. 235.
Complete.
Different from the above only in the end as given below :—

तदनन्तरं पञ्चपूजां कुर्यात् । मनुः—रां रामाय नमः ।
तद्दशांशगायत्री—
दाशरथाय विद्महे सीतावल्लभाय धीमहि । तं नो रामः प्रचोदयात् ॥

No. **7068.** रामषडक्षरीमन्त्रः.
RĀMAṢAḌAKṢARĪMANTRAḤ

Page, 1. Lines, 6 on a page.
Begins on fol. 45*b* of the MS described under No. 5858.
Complete.
Same as the above.

No. 7069. रामषडक्षरीमन्त्रः.

RĀMAṢAḌAKṢARĪMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 13*b* of the MS. described under No. 6045.

Complete.

Similar to the above.

Beginning:

अस्य श्रीरामषडक्षरीमहामन्त्रस्य अगस्त्य ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता; रां बीजं, रूं शक्तिः, रैं कीलकं, मम श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ।

End:

लं इति पञ्चपूजा । अथ मनुः ।

ब्रह्मार्पणं ब्रह्म हविः . . ब्रह्मकर्मसमाधिना ॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात् ।

करोमि यद्यत् सकलं परस्मै श्रीरामचन्द्रेति(न्द्राय) समर्पयामि ॥

No 7070. रामषडक्षरीमन्त्रः.

RĀMAṢAḌAKṢARĪMANTRAḤ.

Substance, palm-leaf. Size, $10\frac{3}{4} \times 1$ inches. Pages, 3. Lines, 3 on a page. Character, Telugu. Condition, injured. Appearance, new.

Incomplete.

Similar to the above.

Beginning:

अस्य श्रीरामषडक्षरीमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, सीतारामो देवता, रां बीजं, रीं शक्तिः, रूं कीलकं, रामषडक्षरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

कालाम्भोधरकान्तिकान्तमनिशं वीरासनेऽध्यासिनं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानु(नि) ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तीं विविधाङ्गदादिमकुटाकल्पोज्ज्वलाङ्गं भजे ॥

लं पृथिव्यादिपञ्चपूजा ॥

No. **7071.** रामषडक्षरीमन्त्रः.

RĀMAṢAḌAKṢARĪMANTRAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 63*a* of the MS. described under No. 21.

Complete.

Different from the above only in the end as given below :—

पञ्चपूजा । मनुः—ओं श्रीं रां रामाय नमः । यथाशक्ति जपः, जपान्ते दिग्विसर्गः ॥

No. **7072.** रामषडक्षरीमन्त्रः.

RĀMAṢAḌAKṢARĪMANTRAḤ.

Pages, 2 Lines, 7 on a page.

Begins on fol. 57*a* of the MS. described under No. 5660.

Complete.

Similar to the above

Beginning :

अस्य श्रीरामषडक्षरीमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीजानकीसहितश्रीरामचन्द्रो देवता; ओं रां बीजं, ओं रीं शक्तिः, ओं रूं कीलकं, मम श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

पञ्चपूजा । मनुः – ओं रां रामाय नमः ।
उत्तरन्यासं कुर्यात् । दिग्विमोकः ॥

No. **7073.** रामषोडशाक्षरीमन्त्रः.

RĀMAṢŌḌAŚĀKṢARĪMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 288*a* of the MS. described under No. 5477, wherein this is found in the Mantramālikā 273*a* given therein in the list of other works.

Complete.

This Mantra as given in the extract is found to consist of more than 16 syllables.

Beginning and **End :**

पुनष्षोडशाक्षरीमन्त्रभेदः—

ओं द्रां दाशरथाय सीतावल्लभाय त्रैलोक्यनाथाय नमः । पूर्ववज्जपहोमः ॥

Colophon :

इति राम(षोडशाक्षरी)मन्त्रभेदः ॥

No. **7074.** रामषोडशाक्षरीमन्त्रः.

RĀMAṢŌḌAŚĀKṢARĪMANTRAḤ.

Pages, 2. Lines, 28 on a page.

Begins on fol. 244*a* of the MS. described under No. 581, wherein this is found in the Mantramālikā 222*a* given in the list of other works contained therein.

Complete.

Similar to the above.

Beginning and **End :**

षोडशाक्षरमन्त्रः प्रकारान्तरम्—

ओं ह्रीं द्रां दाशरथाय सीतावल्लभाय त्रैलोक्यनाथाय नमः ॥

No. **7075.** रामषोडशाक्षरीमन्त्रः.

RĀMAṢŌḌAŚĀKṢARĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 95*a* of the MS. described under No. 5566.

Complete.

Same as the above.

No. 7076. रामषोडशाक्षरीमन्त्रः.
RĀMAṢŌḌAŚĀKṢARĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 95*a* of the MS. described under No. 5566.

Complete.

Same as the above

No 7077. रामषोडशाक्षरीमन्त्रः.
RĀMAṢŌḌAŚĀKṢARĪMANTRAḤ.

Page, 1. Lines, 28 on a page.

Begins on fol. 244*a* of the MS. described under No. 581, wherein this is found in the Mantramālikā given in the list of other works contained therein.

Complete.

This Mantra consists of 16 syllables only, if the last word is not taken into account.

Beginning :

अस्य षोडशाक्षरश्रीराममन्त्रस्य अगस्त्य ऋषिः, बृहती छन्दः, श्रीरामो देवता; हं बीजं, रं शक्तिः, ममेष्टकाम्यार्थसिद्ध्यर्थे विनियोगः ।

End :

नमः सीतापतये रामाय हन हन हुं फट् स्वाहा ॥

No. 7078. रामषोडशाक्षरीमन्त्रः.
RĀMAṢŌḌAŚĀKṢARĪMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 287*b* of the MS. described under No. 5477, wherein this is found in the Mantramālikā 273*a* given in the list of other works contained therein.

Complete.

Same as the above.

No. 7079. रामाष्टादशाक्षरमन्त्रः.
RĀMĀṢṬĀDAŚĀKṢARAMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 17*b* of the MS. described under No. 757, wherein this has been omitted to be included in the other works contained therein

Complete.

This Mantra consists of 18 syllables and is held to be able to secure protection to one at all times.

Beginning:

ओं ह्रीं जानकीवल्लभाय स्वाहेत्याग्नेय्यां मां सदावतु । ओं ह्रीं श्रीं भरताग्रजराम क्लीं स्वाहेति पातु मां नैरृत्यां सदा प्रभुः । ओं श्रीं जानकीवल्लभाय स्वाहा इति वायव्यां(व्यायां) मां सदावतु ।

End:

ओं नमो भगवते रामाय महापुरुषाय नमः । इत्यष्टादशाक्षरो मन्त्रो मामेव सर्वदावतु ॥

No. 7080. राशिन्यासः.
RĀŚINYĀSAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 44*b* of the MS. described under No. 673.

Complete.

On the ceremonial touching of certain parts of the body while repeating the Mantra-formula formed by combining the successive letters of the alphabet with each of the names of the twelve constellations which constitute the zodiacal signs.

Beginning:

अथ राशिन्यासः—

रक्तं श्वेतं हरिद्वर्णं पाण्डु चित्रं सितं स्मरेत् ।
पिशङ्गपिङ्गलौ बभ्रुकर्बुरा नीलधूम्रकाः ॥

इति ध्यात्वा अं आं इं ईं मेषराशये नमः दक्षगुल्फे, उं ऊं वृषभराशये नमः दक्षजानुनि, ऋं ॠं मिथुनराशये नमः दक्षवृषणे।

End:

ओं तं थं दं धं मकरराशये नमः वामवृषणे, पं फं बं भं कुम्भराशये नमः वामजानुनि, यं रं लं वं शं षं मनिराशये नमः वामगुल्फे, इति मातृकावर्णैः न्यस्येत् ॥

Colophon:

इति राशिन्याससमाप्तः ॥

No. **7081.** राहुकवचम्.

RĀHUKAVACAM.

Pages, 2. Lines, 19 on a page.

Begins on fol. 51*a* of the MS. described under No. 2886, wherein it has been given as Navagrahakavacam in the list of other works given therein.

Complete.

Addressed to Rāhu considered to be a planet. This Mantra is intended to propitiate that planet.

Beginning:

अस्य श्रीराहुकवचस्तोत्रमहामन्त्रस्य चन्द्र ऋषिः, अनुष्टुप्, राहुर्देवता; सर्वाभीष्ट—गः ।

* * * *

नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे मेऽर्धशरीरवान् ॥

End:

स्वर्भानुर्जानुनी पातु जङ्घे मे पातु चाप्यहिः ।
गुल्फौ ग्रहाधिपः पातु नीलचन्दन. . . . ॥

No. 7082. राहुमन्त्रः.
RĀHUMANTRAH.

Page, 1. Lines, 18 on a page.

Begins on fol. 311*b* of the MS. described under No. 5477.

Complete.

Similar to the above.

Beginning:

अस्य श्रीराहुग्रहमन्त्रस्य वामदेव ऋषिः, राहुर्देवता, गायत्री छन्दः, मम राहुप्रसादसिद्ध्यर्थे विनियोगः ।

End:

मन्त्रः—ओं ह्रां ह्रीं ह्रूं राहवे नमः। लक्षं जपः। दशांशहोमः॥

No. 7083. रुद्रकवचम्.
RUDRAKAVACAM.

Pages, 5. Lines, 5 on a page.

Begins on fol. 73*a* of the MS. described under No. 132

Complete as found in the Vāyupurāṇa.

This Kavacamantra is addressed to Rudra, i.e., Śiva; and its repetition is held to enable one to secure his favour and protection.

Beginning:

अस्य श्रीरुद्रकवचस्तोत्रमहामन्त्रस्य अनुष्टुप् छन्दः, श्रीदुर्वासा ऋषिः, श्रीमहारुद्रो देवता; ओं बीजं, ह्रीं शक्तिः, श्रीः कीलकं, मम कायजीवसंरक्षणार्थे श्रीमहादेवप्रसादसिद्ध्यर्थे जपे विनियोगः ।

* * * *

प्रणम्य शिरसा रुद्रं स्वयम्भूर्भुवनेश्वरः ।
एकं सर्वगतं देवं सर्वदेवमयं प्रभुम् ॥
रुद्रकौचं प्रवक्ष्यामि अङ्गप्राणसुरक्षितम् ।
अहोरात्रं महादेव रक्षाभू(यै)देवनिर्मितम् ॥

ब्रह्मोवाच—

रुद्रो ममाग्रतः पातु पृष्ठतः पातु शङ्करः ।
कपर्दी दक्षिणं पातु वामपार्श्वे तथा हरः ॥

End:

त्राहि त्राहि जगन्नाथ त्राहि त्राहि जगन्मय ।
त्राहि मां पार्वतीकान्त त्राहि मां भक्तवत्सल ॥
आसन्ध्यं कीर्तयेच्छक्त्या प्रयाति परमां गतिम् ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥

Colophon:

इति वायुपुराणे रुद्रकवचं संपूर्णम् ॥

No. **7084.** रुद्रकवचम्.

RUDRAKAVACAM.

Pages, 2. Lines, 8 on a page.

Begins on fol. 130*a* of the MS. described under No 119.

Complete.

Similar to the above.

The popular belief regarding the religious efficacy of this Mantra is well expressed in the concluding stanzas

Beginning:

अस्य रुद्रकवचस्य अनुष्टुप् छन्दः, दूर्वासभगवानृषिः, त्रियम्बकरुद्रो देवता ; ह्रीं बीजं, ह्रों शक्तिः, ह्रैं कीलकं, श्रीसदाशिवमहादेवप्रीत्यर्थे जपे विनियोगः ।

प्रणम्य शिरसा देवं सर्वदेवमयं प्रभुम् ।
महादेवप्रसादेन दूर्वासमुनिकल्पितम् ॥
अथातो रुद्रकवचं प्रवक्ष्याम्यानुपूर्विकम् ।
रहस्यं देवदेवेश रक्षार्थं निर्मित (तं)पुरा ॥
रुद्रो मामग्रतः पातु पृष्ठतः पातु शङ्करः ।
कपर्दी दक्षिणे पातु वामपार्श्वे हरो हरः ।

End:

पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम्।
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥
इत्येतद्रुद्रकवचं पवित्रं पापनाशनम् ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥

Colophon:

श्रीरुद्रकवचं संपूर्णम् ॥

No. **7085.** रुद्रकवचम्.
RUDRAKAVACAM.

Pages, 3. Lines, 8 on a page.
Begins on fol. 148*a* of the MS. described under No. 781.
Complete.
Similar to the above.

Beginning:

प्रणम्य शिरसा देवं स्वयंभूर्भुवनेश्वरः ।
एकं सर्वगतन्देवं सर्वलोकमहेश्वरम् ॥
रुद्रकौचं प्रवक्ष्यामि अङ्गप्राणाभिरक्षितम् ।
अहोरात्रं प्रसादेन रक्षार्थं देवनिर्मितम् ॥

अस्य श्रीरुद्रकवचस्तोत्रमन्त्रस्य अघोर ऋषिः, अनुष्टुप् छन्दः, मृत्युञ्जयत्रियम्बकरुद्रो देवता; ह्रां बीजं, श्रीः शक्तिः, ह्रूं कीलकं, मम इष्टकाम्यार्थनित्या(सिद्ध्य)र्थे श्रीरुद्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

* * * *

रुद्रो ममाग्रतः पातु पृष्ठतः पातु शङ्करः ।

End:

त्राहि मां पार्वतीनाथ त्राहि मां त्रिपुरान्तक ।
त्रिसन्ध्यं कीर्तयेद्भक्त्या प्राप्नोति परमां गतिम् ॥

Colophon:

रुद्रकवचं संपूर्णम् ॥

No. 7086. रुद्रकवचम्.
RUDRAKAVACAM.

Pages, 6. Lines, 5 on a page.

Begins on fol. 21*a* of the MS. described under No. 5422.

Complete.

Same as the above.

No. 7087. रुद्रकवचम्.
RUDRAKAVACAM.

Pages, 8. Lines, 5 on a page.

Begins on fol. 53*a* of the MS. described under No. 6600.

Complete.

Same as the above.

No. 7088. रुद्रमालामन्त्रः.
RUDRAMĀLĀMANTRAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol 84*b* of the MS. described under No 21, wherein it is given as Rudramantra.

Complete.

This Mantra, which praises Rudra under different significant names, is held to have the power to secure protection to one, to cause annoyance to one's enemies in various ways, to drive off evil spirits, and to counteract the effects of hostile Mantras, etc.

Beginning :

शरीररक्षणरुद्रमन्त्रः—

ओं नमः पशुपतये नानाभूताधिपतये ओं नमो रुद्राय ल ल ल ल ल ल ल खड्गरावणबलिं विहर नृत्य नृत्य श्मशानभस्मार्चितशरीराय उग्रतेजोमयाय.

End :

विध्वंस विध्वंस प्रवेशय प्रवेशय आवेशय आवेशय पूर्वप्रतिष्ठानां साधु शोषाय परविद्याच्छेदनाय ह्रां ह्रीं हुं फट् शिवाय इति उच्चाटनम्॥

No. **7089.** रुद्रहृदयम्.

RUDRAHṚDAYAM.

Pages, 3. Lines, 5 on a page.

Begins on fol. 67*a* of the MS. described under No. 132.

Complete as found in the Skāndapurāṇa.

This Mantra is also addressed to Rudra. Its repetition is held to be efficacious in removing one's sins, in conferring prosperity and long life on one, and in enabling one to obtain salvation. The word Hṛdaya as applied to Mantras indicates their high religious value and mystic efficacy and importance.

Beginning:

अस्य श्रीरुद्रहृदयस्तोत्रमन्त्रस्य नन्दिकेश्वर ऋषिः, सदाशिवो देवता, अनुष्टुप् छन्दः, सदाशिवप्रीत्यर्थे रुद्रहृदयस्तोत्रपठने विनियोगः ।

ओङ्काराय विरूपाय विशुद्धाय नमो नमः ।
शम्भुस्स्ववि(यं)भु(भू)र्भगवान् भूर्भूदाय नमो नमः ॥
अग्निमीळे नमस्तुभ्यं मा नस्तोके नमो नमः ।
अग्नये रुद्ररूपाय अग्न आ याहि वीतये ॥

End:

रुद्रस्य हृदयं प्रोक्तं स्तवं नन्दिमुखेहृद(रित)म् ।
त्रिसन्ध्यं यः पठत् स्तोत्रं सोऽपि सायुज्यमाप्नुयात् ॥
भ्रूणहत्यादिकं पापं स्मरणादेव नश्यति ।
किमत्र बहुनोक्तेन पापं यत् पूर्वसञ्चितम् ॥
तत्सर्वं नश्यति क्षिप्रं स्तोत्रपाठान्न संशयः ।
आयुरारोग्यमश्वर्यज्ञानवित्तप्रदं भवेत् ॥

Colophon:

इति श्रीमत्स्कान्दे काशिखण्डे नन्दिकेश्वरप्रोक्ते रुद्रहृदयं समाप्तम् ॥

No. 7090 रुद्रहृदयम्.
RUDRAHṚDAYAM.

Pages, 9. Lines, 5 on a page.
Begins on fol. 48*a* of the MS. described under No. 5836.
Complete.
Same as the above.

No. 7091. रुद्रहृदयम्.
RUDRAHṚDAYAM.

Pages. 4. Lines, 6 on a page
Begins on fol. 96*b* of the MS. described under No. 119.
Complete.
Similar to the above.

Beginning:

अस्य श्रीरुद्रहृदयस्तोत्रमन्त्रस्य वेदव्यास ऋषिः, अनुष्टुप् छन्दः, ... येति शक्तिः, नम इति कीलकं, श्रीउमामहेश्वरप्रीत्यर्थे विनियोगः ।

शुक उवाच--
देवेशस्सर्वदेवेषु कस्मिन् देवाश्च सर्वशः ।
कस्य शुश्रुम . . . . . भवन्ति च ॥
तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुकम् ।
श्रीवेदव्यास उवाच—
सर्वदेवात्मको रुद्रस्सर्वे देवाश्शिवात्मकाः ।

* * * *

रुद्रो दे(दि)वा उमा रात्रिस्तस्मै तस्यै नमो नमः ।
रुद्रो याग उमा वेदिस्तस्मै तस्यै नमो नमः ॥

End:

यत्र यत्र भवेत् साध्यामिमं मन्त्रमुदीरयेत् ।
रुद्रस्य हृदयं पुण्यमेवमेतदनामयम् ॥

दिव्यं च दैवतानां च सर्वस्य जगतः प्रियम् ।

* * * *

देवतायतने पक्षं मासं पक्षार्धमेव वा ।
ब्रह्मविष्णुमहेशानां क्रमाल्लोकानवाप्नुयात् ॥

Colophon:

श्रीउमामहेश्वरे रुद्रहृदयं संपूर्णम् ॥

No. 7092. रुद्रहोमः.

RUDRAHŌMAḤ.

Pages, 20. Lines, 4 on a page.

Begins on fol. 162*a* of the MS. described under No. 6414.

Complete.

On a fire-offering to propitiate Rudra by repeating the Vēdic passages forming the 5th Praśna in the 4th Kāṇḍa of the Taittirīya-Saṁhitā. This offering is considered to have the effect of averting evils of various kinds.

The Vēdic sentences are only indicated here by their beginnings.

Beginning:

नमस्ते रुद्र . . . नमः स्वाहा—रुद्राय इदं,
या त इषुः . . . मृडय स्वाहा—रुद्राय इदं,
या ते रुद्र शिवा . . चाकशीहि स्वाहा—मम.
यामिषुं गिरिशन्त . . जगत् स्वाहा—रुद्राय मम,
शिवेन वचसा त्वा . . सुमना असत् स्वाहा—रुद्राय ।

End:

वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमः . . . दधामि स्वाहा—रु ॥

* * * *

स्यक्षा रुद्राक्षमालासुललितवपुषश्शाम्भवा मूर्तिभेदाः रुद्राश्श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ।

* * * *

अयं मे हस्तो भगवानयं मे भगवत्तरः । अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥

No. 7093. रुद्राध्यायमन्त्रः.

RUDRĀDHYĀYAMANTRAḤ.

Pages, 2 Lines, 4 on a page.

Begins on fol. 16*a* of the MS. described under No. 2279.

Complete.

This Mantra is in praise of Rudra. The Vēdic passages to be repeated are the same as those used in connection with the Rudrahōma noticed under the previous number.

Beginning:

अस्य श्रीरुद्राध्यायमन्त्रस्य अग्निकाण्ड ऋषिः, महाविराट् छन्दः, शम्भुर्देवता; नमस्ते रुद्र मन्यव इति बीजं, सहस्राणि सहस्रशो य इति शक्तिः, नमस्तारायेति कीलकं, मम शम्भुप्रीत्यर्थे जपे विनियोगः ।

End:

शुद्धस्फटिकसङ्काशं शुद्धविद्याप्रदं मृडम् ।
शुद्धं सच्चित्सुखानन्दं शुद्धं पूर्णमहं भजे ॥

ओं नमो भगवते रुद्राय । इमं मन्त्रं दशकृत्वः शतकृत्वः सहस्रकृत्वो वा जपित्वा रुद्रोक्तप्रकारेण जपेत् ॥

No. 7094. रेणुकापरमेश्वरीमन्त्रः.

RĒṆUKĀPARAMĒŚVARĪMANTRAḤ.

Page, 1. Lines, 6 on a page

Begins on fol. 117*a* of the MS. described under No. 5417.

Complete.

Rēṇukā referred to herein is probably the wife of Jamadagni and the mother of Paraśurāma. She is considered to be the presiding deity of small-pox and such other epidemics. The repetition of this Mantra is held to enable one to bring people under one's control and to annoy one's enemies in various ways.

Beginning :

अस्य श्रीरेणुकापरमेश्वरीमन्त्रस्य जमदग्निः ऋषिः, पङ्क्तिश्छन्दः, श्रीरेणुकापरमेश्वरी देवता ; ह्रीं बीजं, स्वाहा शक्तिः, रेणुकापरमेश्वरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

ओं ह्रीं नमो भगवति रक्तपक्ष्मि रेणुकादेवि दह दह पच पच अखिलजगन्मे वशं कुरु कुरु स्वाहा ।

ह्रीं इत्याद्यष्टत्रिंशद्वर्णैर्मूलमन्त्र . . . . इष्टार्थं भवति प्रसिद्धम् ॥

No. 7095. लक्ष्मीकवचः.

LAKṢMĪKAVACAḤ.

Pages, 5. Lines, 18 on a page.

Begins on fol. 138*b* of the MS. described under No. 2373.

Complete.

This Mantra is addressed to Lakṣmī, and its repetition is held to have the power to remove one's sins, to secure protection to one from bad people and evil spirits, to remove diseases, and to confer prosperity on one, etc.

Beginning :

लक्ष्मीकवचम् ।

श्रीदेव्युवाच —

महालक्ष्मि(क्ष्म्याः) प्रवक्ष्यामि कवचं सर्वकामदम् ।
सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥

ग्रहपीडाप्रशमनमरिष्टव्र(व्रा)तभञ्जनम् ।
पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् ॥

* * * *

महालक्ष्मीश्शिरः पातु ललाटं पङ्कजालया ।
कर्णौ मम रमा पातु नयने नलिनालया ॥

End:

यासापद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिस्स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

Colophon:

इति श्रीलक्ष्मीकवचं संपूर्णम् ॥

No. 7096. लक्ष्मीकवचः.
LAKṢMĪKAVACAḤ.

Substance, palm-leaf. **Size**, 7¾ × 1¼ inches. **Pages**, 6. **Lines**, 4 on a page. **Character**, Grantha. **Condition**, much injured. **Appearance**, new.

Begins on fol. 21*a*. The other works herein are **Bhagavadārādhana** 1*a*, Jitantēstōtra 12*a*, Paścimaraṅgamaṅgalāśaṁsana 24*a*.

Complete as found in the Varāhapurāṇa.

Similar to the above.

Beginning:

इन्द्र उवाच—

समस्तकवचानां च तेजश्श्रीकरमुत्तमम् ।
आयूरक्षणमारोग्यं सर्वं वै ब्रूहि गीष्पते ॥

गुरुरुवाच—

कवचस्मरणं नित्यं कुरु त्वममरेश्वर ।
चतुर्दशसु लोकेषु रहस्यं ब्रह्मनिर्मितम् ॥

शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा ।
चक्षुः पातु विशालाक्षी श्रवणं सागरात्मजा ॥

End :

ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं शुभम् ।
ये पठन्ति महात्मानस्ते वै रम्या जगत्पतेः ॥
आयुर्वृद्धिस्तथैवात्र पूर्वोक्ता ब्रह्मणा पुरा ।
मघवन् तन्मयाख्यातं सर्वाभीष्टफलप्रदम् ॥

Colophon :

इति श्रीवराहपुराणे लक्ष्मीकवचं संपूर्णम् ॥

No. 7097. लक्ष्मीकवचः.

LAKṢMĪKAVACAḤ.

Substance, palm-leaf. Size, 16¼ × 1⅜ inches. Pages, 7. Lines, 6 on a page. Character, Grantha. Condition, much injured. Appearance, old.

Begins on fol. 24*a*. The other works herein are Apāmārjana-nyāsa 1*a*, Apāmārjanakavaca 5*a*, Apāmārjanastōtra 8*b*, Sudarśana-yantrōddhāra 28*a*, Lakṣmīstōtra 36*a*, Bhāgavataślōka 32*a*, Nālavēṣṭanaśānti 38*a*, Pakṣiṇyāśaucanirṇaya 40*a*.

Complete.

Similar to the above.

Beginning :

क्षीराब्धिमध्ये कल्पद्रुकानने दिव्यमण्टपे ।
सिंहासनस्थितां देवीममरीजनसेविताम् ॥
सुस्नातां पुष्पसुभगां कटकावलिभूषिताम् ।

* * * *

महालक्ष्मीः शिरः पातु ललाटं मम पद्मजा ।
कर्णौ रक्षेद्रमा पातु नयने नलिनालया ॥

End:

य इदं कवचं दिव्यं रमायाः प्रयतः पठेत् ।
सर्वसिद्धिमवाप्नोति सर्वरक्षां तु शाश्वतीम् ॥

* * * *

एवं देवीप्रसादेन शुकः कवचमाप्तवान् ।
कवचानुग्रहेणैव सर्वान् कामानवाप्नुयात् ॥

Colophon:

इति शुकब्रह्मसंवादे महालक्ष्मीकवचं सम्पूर्णम् ॥

No. **7098.** लक्ष्मीगणपतिमन्त्रः.

LAKṢMĪGAṆAPATIMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 125*a* of the MS. described under No. 29.

Complete.

This Mantra is addressed to Lakṣmīgaṇapati, one of the manifestations of Vināyaka. Its repetition is held to enable one to accomplish one's desires and to bring all people under one's influence and control.

Beginning:

अस्य श्रीलक्ष्मीगणपतिमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, ग्लां बीजं, ग्लीं शक्तिः, ग्लूं कीलकं, मम इष्टकाम्यार्थसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं श्लूं ह्रीं श्रीं क्लीं ग्लां गं गणपतये वरवरद सर्वजनं मे वश-मानय स्वाहा ॥

No. **7099.** लक्ष्मीगणपतिमन्त्रः.

LAKṢMĪGAṆAPATIMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 20*b* of the MS. described under No. 5928, wherein this Mantra has been omitted to be included among the other works given therein.

Complete.

Similar to the above. Held also to propitiate Dakṣiṇāmūrti or Śiva.

Beginning:

अस्य श्रीलक्ष्मीगणपतिमहामन्त्रस्य गणक ऋषिः, निचृद्गायत्री छन्दः, श्रीमहालक्ष्मीगणपतिर्देवता; गं बीजं, श्रीं शक्तिः, ग्लौं कीलकं, श्रीदक्षिणामूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ॥

श्रीलक्ष्मीगणपतिपादुकां पूजयामि ॥

No. 7100. लक्ष्मीगणेशमन्त्रः.

LAKṢMĪGAṆEŚAMANTRAḤ.

Pages, 2. Lines, 20 on a page.

Begins on fol. 65*a* of the MS. described under No. 426.

Complete.

Similar to the above.

Beginning:

अस्य श्रीलक्ष्मीगणपतिस्तोत्रमहामन्त्रस्य गणक ऋषिः, निचृद्गायत्री छन्दः, श्रीमहागणपतिर्देवता; ग बीजं, स्वाहा शक्तिः, ग्लौं कीलकं, मम सर्वाभीष्टफलसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये नमो वरवरद सर्वजनं मे वशमानय स्वाहा ॥

Colophon:

इति लक्ष्मीगणेशस्तोत्रं समाप्तम् ॥

No. 7101. लक्ष्मीनारायणकवचः.
LAKṢMĪNĀRĀYAṆAKAVACAḤ.

Pages, 6. Lines, 14 on a page.

Begins on fol. 120*b* of the MS. described under No. 5673.

Complete.

This forms the 38th Paṭala of Rudrayāmala.

This Mantra is addressed to Nārāyaṇa as associated with Lakṣmī. Its repetition is held to have the power to confer on one prosperity and happiness during life, and salvation after death.

Beginning:

भैरव उवाच—

अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते ।
कवचं मन्त्रगर्भञ्च वज्रपञ्जरकाख्यया ॥
श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् ।
रहस्यं सर्वदेवानां साधकानां विशेषतः ॥

* * * *

कवचस्यास्य सुभगे कथितोऽयं शिवो मुनिः ।
त्रिष्टुप् छन्दो देवता च लक्ष्मीनारायणो मतः ॥
रमा बीजं परा शक्तिस्तारं कीलकमीश्वरि ।
भोगापवर्गसिद्ध्यर्थे विनियोग इतीरितः ॥

* * * *

ओं वासुदेवोऽवतु मे मस्तकं सशिरोरुहम् ।
ह्रीं ललाटं सदा पातु लक्ष्मीर्विष्णुस्सनातनः ॥

End:

त्रिसन्ध्यं यः पठेन्नित्यं कवचं मन्मुखोदितम् ।
स याति परमं धाम वैष्णवं वैष्णवेश्वरः ॥
महाजनपदस्थोऽपि यः पठेदात्मचिन्तकः ।
आनन्दघूर्णितस्तूर्णं लभेन्मोक्षं स साधकः

गन्धाष्टकेन विलिखेद्द्वौ भूर्जे जपेन्मनुम् ।
पीतसूत्रेण संवेष्ट्य सौवर्णेनाथ वेष्टयेत् ॥
धारयेद्ध(द्वु)टिकां मूर्ध्नि लक्ष्मीनारायणं स्मरन् ।
रणे रिपून् विजित्याशु कल्याणी गृहमादिश(विशे)त् ॥

No. 7102. लक्ष्मीनारायणहृदयम्.
LAKṢMĪNĀRĀYAṆAHṚDAYAM.

Pages, 5. Lines, 14 on a page.

Begins on fol. 118*a* of the MS. described under No. 5673.

Complete as found in the Atharvaṇarahasya.

This Mantra is believed to have the power to secure the favour of Lakṣmīnārāyaṇa.

Beginning:

अस्य श्रीलक्ष्मीनारायणहृदयस्तोत्रमहामन्त्रस्य भार्गव ऋषिः, अनुष्टुप् छन्दः, श्रीलक्ष्मीनारायणो देवता; ओं बीजं, ह्रीं शक्तिः, रं कीलकं, मम श्रीमन्नारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।

* * * *

नारायणः परं ज्योतिरात्मा नारायणः परः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥
नारायणः परो देवो दाता नारायणः परः ।
नारायणः परं धाम नारायण नमोऽस्तु ते ॥

End:

नारायणस्य हृदयमादौ जप्त्वा ततः परम् ।
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ॥
पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीहृदं जपेत् ।

* * * *

गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ॥

Colophon :

इति श्रीअथर्वणरहस्ये उत्तरभागे श्रीनारायणहृदयं स्तोत्रं संपूर्णम् ॥

No. **7103.** लक्ष्मीनारायणहृदयम्.
LAKṢMĪNĀRĀYAṆAHṚDAYAM.

Substance, palm-leaf. Size, 15¾ × 1⅜ inches. Pages, 6. Lines, 6 on a page. Character, Grantha. Condition, injured. Appearance, old.

Begins on fol. 1*a*. The other works herein are Lakṣmīhṛdayastōtramantra 4*a*, Lakṣmīstōtramantra 4*b*, Lakṣmīhṛdayadhyāna 5*b*, Avadhūtagītā 12*a*

Complete as found in the Atharvaṇarahasya.

Similar to the above.

The word आद्यादि appended to Lakṣmī is probably intended to convey the idea that she is the primal cause of all things in the universe.

Beginning :

अस्य श्रीमदथर्वण श्रीमदाद्यादिविजयमहालक्ष्मीनारायणहृदयस्तोत्रमहामन्त्रस्य भार्गव ऋषिः, अनुष्टुप् छन्दः, श्रीमदथर्वण . . लक्ष्मीनारायणो देवता; ओं श्रीं बीजं, ओं ह्रीं शक्तिः, ओं ऐं कीलकं, श्रीमदाद्यादिश्रीविजयमहालक्ष्मीनारायणप्रसादासिद्ध्यर्थे श्रीमदथर्वणश्रीमदाद्यादिश्रीविजयमहालक्ष्मीनारायणहृदयजपे विनियोगः ।

End :

ओं ऐं ह्रीं श्रीं क्लीं कमलधारिणि महालक्ष्मीनारायणाय सिद्धिवाहिनि वषट् स्वाहा ॥

Colophon :

इत्याथर्वणरहस्ये उत्तरखण्डे श्रीमदाद्यादिश्रीविजयलक्ष्मीनारायणहृदयम् ॥

No. **7104.** लक्ष्मीनृसिंहमन्त्रः.
LAKSMĪNRSIMHAMANTRAH.

Page, 1. Lines, 18 on a page.

Begins on fol 2?0a of the MS. described under No. **5477**, wherein this Mantra is found in the Mantramālikā 273*a*, given therein in the list of other works.

Complete.

The repetition of this Mantra is held to have the power to secure the favour of Laksmīnrsimha, i.e., Nrsimha as associated with Laksmī

Beginning:

अस्य श्रीलक्ष्मीनृसिंहमन्त्रस्य ब्रह्मा ऋषिः, त्रिष्टुप् छन्दः, श्रीलक्ष्मीनृसिंहो देवता; ईं बीजं, क्ष्रौं शक्तिः, (त्रि)विध[त्रि]कालपुरुषदेवः अधिदेवता, प्रह्लादप्रह्लादः प्रत्यधिदेवता, मम लक्ष्मीनृसिंहप्रसादसिद्ध्यर्थे विनियोगः ।

End:

हं ईं क्ष्रौं श्रीं लक्ष्मीनृसिंहाय नमः ॥

No. **7105.** लक्ष्मीनृसिंहमन्त्रः
LAKSMĪNRSIMHAMANTRAH.

Pages, 2. Lines, 27 on a page.

Begins on fol. 252*a* of the MS. described under No. 581, wherein this Mantra is found in the Mantramālikā 22*a*, given therein in the list of other works.

Complete.

Same as the above

No. **7106.** लक्ष्मीनृसिंहमन्त्रः.
LAKSMĪNRSIMHAMANTRAH.

Page, 1. Lines, 10 on a page.

Begins on fol. 100*a* of the MS. described under No. **5566**, wherein apparently it has been omitted to be given in the list of other works.

Complete.

Same as the above.

No. 7107. लक्ष्मीनृसिंहमन्त्रः.
LAKṢMĪNṚSIṀHAMANTRAḤ

Pages, 2. Lines, 4 on a page.

Begins on fol. 23a of the MS. described under No. 3862.

Complete.

Similar to the above.

Beginning and **End**:

अव्यान्निर्व्याजरौद्राकृतिकृतविलसास्योल्लसत्तीक्ष्णदंष्ट्रं(ष्ट्रः)
चक्रं शङ्खं च पाशाङ्कुशकुलिशगदादारुणासीन्दधानः ।
रक्ताकारं च नाभेरधउपरिलसद्दिव्यभूषाविशेषो
देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं नः ॥
ह्रां ह्रीं क्ष्रौं क्रौं हुम्फट् ॥

No 7108. लक्ष्मीनृसिंहमन्त्रः.
LAKṢMĪNṚSIṀHAMANTRAḤ.

Pages, 4. Lines, 6 on a page.

Begins on fol. 62a of the MS. described under No. 5819.

Complete.

Similar to the above.

Beginning:

आसनं परिकल्प्य, भद्रं कर्णेभिरिति शान्तिं पठित्वा, अस्य श्रीलक्ष्मीनृसिंहैकाक्षरमन्त्रस्य अत्रिः ऋषिः, जगती छन्दः, एकाक्षरीनृसिंहो महाविष्णुर्देवता, ह्रीं बीजं, क्ष्रौं शक्तिः, लक्ष्मीनृसिंहप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

जान्वोरासक्ततीक्ष्णस्वनखरुचिलसद्बाहुसंश्लिष्टकेशं
शङ्खं चक्रं च दोर्भ्यां ज्वलदनलनिभज्योतिषाभुग्नदैत्यम् ।
ज्वालामालापरीतं रविशशिदहनत्र्यक्षदीप्तोग्रदंष्ट्रं
व्यात्ता(त्ता)स्यं धूम्रकेशं वदनमपि महत् पातु मां नारसिंहम् ॥

यथाशक्ति जपित्वा हृदयादिन्यासं कृत्वा ध्यानश्लोकं पठेत् । भद्रं कर्णेभिरिति शान्तिं पठेत् । उपसंहारमुद्रां प्रदर्शयेत् । ओं क्ष्रोम् ॥

Colophon:

इति मूलमन्त्रः ॥

No. **7109.** लक्ष्मीनृसिंहमन्त्रराजमन्त्रः.

LAKṢMĪNṚSIṀHAMANTRARĀJAMANTRAḤ.

Pages, 3. Lines, 9 on a page.

Begins on fol. 21*b* of the MS. described under No. 6090, wherein it has been given as Nṛsiṁhamantrōddhāra in the list of other works contaiud therein.

Complete.

This is the most important of the Mantras addressed to Lakṣmīnṛsiṁha.

Beginning:

अस्य श्रीलक्ष्मीनृसिंहानुष्टुभमन्त्रराजमहामन्त्रस्य विधिब्रह्मप्रजापति. ऋषयः मूर्ध्नि, अनुष्टुप् छन्दः मुखे, श्रीभगवान् श्रीमङ्गलेश्वरः श्री· लक्ष्मीनृसिंहपरमात्मा देवता हृदये; हं बीजं नाभौ, ई शक्तिः गुह्ये, ओं कीलकं पादयोः, मम श्रीलक्ष्मीनृसिंहप्रसादसिद्ध्यर्थे जपे विनि- योगः ।

End:

हं ई ओं ओं हं ।

उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥

पुनः न्यासध्यानपञ्चपूजां कुर्यात् । तर्पणहोमब्राह्मणभोजनगोदा- नादिसमस्तदानानि कुर्यात् ॥

No. 7110. लक्ष्मीपञ्जरम्.
LAKṢMĪPAÑJARAM.

Pages, 3. Lines, 18 on a page.

Begins on fol. 140*b* of the MS. described under No. 2373, wherein this Mantra has been omitted to be given in the list of other works.

Incomplete.

This Mantra is addressed to the goddess Lakṣmī. Its repetition is believed to have the power to remove one's poverty and to make one wealthy.

Beginning

क्षीरार्णवसमुद्भूते श्वेतद्वीपनिवासिनि ।
नारायणस्य हृत्पद्मवासिनि ते नमोऽस्तु ते ॥
कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् ।
ऋषयस्ततः सङ्गम्य प्रणिपत्य यथाक्रमम् ॥

ऋषय ऊचुः—

येन केन प्रकारेण दारिद्र्यं नाशयत्यसौ ।
दारिद्र्येण तपोनाशः देशनाशं दरिद्रता ॥

ईश्वर उवाच—

शृणु ब्रह्मज्ञ देवर्षे महालक्ष्मीमनुस्मरन् ।
तस्याराधनमात्रेण चञ्चला सुस्थिरा भवेत् ॥

End:

मन्त्रपञ्जरकं ब्रह्म सर्वसम्पत्करं शुभम् ।
नरो नारी पठेन्मन्त्रं सर्वदारिद्र्यनाशनम् ॥
यस्य गृहे पुस्तकमिदं लिखितं पुस्तकं तथा ।

* * * *

अचला भव सुप्रीता निर्मलैर्मङ्गलैश्शुभैः ॥
करुणारससन्दोहे कृपां कुरु मम(मा)नघे ।
फलद्भाग्योदया देवी धनं देहि हरिप्रिये ॥

No 7111 लक्ष्मीमन्त्रः.

LAKṢMĪMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 51*b* of the MS. described under No. 2965

Complete.

The repetition of this Mantra is believed to have the power to secure the favour of Lakṣmī and Nārāyaṇa

Beginning:

अस्य श्रीमहालक्ष्मीमन्त्रस्य ईश्वर ऋषिः, गायत्री छन्दः, श्री देवता, श्रीलक्ष्मीनारायणप्रीत्यर्थे जपे विनियोग ।

End:

भां भार्गव्यै नमः ।

अप्रमेयप्रभावस्य विष्णोः पत्नीं जगन्मयीम् ।

मातरं सर्वलोकानां प्रपद्ये शरणं श्रियम् ।

No. 7112. लक्ष्मीमन्त्रः.

LAKṢMĪMANTRAḤ

Page, 1. Lines, 18 on a page.

Begins on fol. 45*a* of the MS. described under No. 2886, wherein it is found in the Ākāśabhairavakalpa 38*a* given therein in the list of other works.

Complete

Similar to the above.

Beginning:

लक्ष्म्याः वामेशः, बार्हती, सर्वस्मृद्धये, सर्वलोकवशीकारे । लक्ष्मीबीजस्य भेदेन न्यासः ।

End:

प्रणवं च रमां मारं महालक्ष्मीपदद्वयम् ।

एह्येहि सर्वसौभाग्यं देहि मे तु ततः परम् ॥

* * * *

चतुर्विंशत्सहस्रं जपः पूर्ववत्तर्पणादि ।

त्रिकोणे तु त्रिबीजं स्याद्वसुकोणं परं लिखेत् ।

त्रयोदशदले शेषं बाह्ये पञ्चाशवर्णकम् ॥

लक्ष्मीबीजावृतं यन्त्रं सर्वसौभाग्यदायकम् ।

No. 7113. लक्ष्मीमन्त्रः.
LAKṢMĪMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 19*b* of the MS. described under No. 5786.

Complete.

Similar to the above. The Mantra consists of only one syllable, viz., **श्रीं**, which is here the typical mystic word signifying the goddess Lakṣmī.

Beginning:

ओं श्रीं ओं इति प्राणायामः १६.

* * * *

अस्य श्रीश्रीबीजलक्ष्मीमन्त्रस्य भृगुः ऋषिः, [यनामिका] गायत्री छन्दः, श्रीनामिका लक्ष्मीर्देवता ; लक्ष्मीप्रेरणया लक्ष्मीप्रीत्यर्थे श्रीमित्येकाक्षरमन्त्रजपे विनियोगः ।

End:

लक्ष्मीप्रेरणया लक्ष्मीप्रीत्यर्थमेकाक्षरश्रीबीजलक्ष्मीमन्त्रजपङ्करिष्ये— ओं श्रीं ओं इति जपः । उपसंहारः पूर्ववत् ॥

No. 7114. लक्ष्मीमन्त्रः.
LAKṢMĪMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 19*b* of the MS. described under No. 5786.

Complete.

Here **ह्रीं** is made to denote mystically the goddess Lakṣmī ; and the Mantra consists of that syllable

Beginning :

गुरुनमस्कारः। ओं ह्रीं ओं इति प्राणायामः १२.

* * * *

अस्य श्रीह्रीबीजलक्ष्मीमन्त्रस्य ब्रह्मा ऋषिः, शक्तिरेवाक्षर ऋषिः, गायत्री छन्दः, ह्रींनामिका लक्ष्मीर्देवता ; लक्ष्मीप्रेरणया लक्ष्मीप्रीत्यर्थे ह्रीमीत्येकाक्षरमन्त्रजपे विनियोगः ।

End :

लक्ष्मीप्रेरणया लक्ष्मीप्रीत्यर्थं ह्रीमित्येकाक्षरलक्ष्मीमन्त्रजपं करिष्ये— ओं ह्रीं ओं इति जपः। उपसंहारः पूर्ववत् ॥

No. **7115.** लक्ष्मीसूक्तम्.

LAKṢMĪSŪKTAM.

Pages, 2. Lines, 8 on a page.

Begins on fol. 19*a* of the MS. described under No. 5786.

Complete.

This Mantra is a Vedic hymn in praise of the goddess Lakṣmī.

Beginning :

गुरुनमस्कारः । ओं श्रीं ओं इति प्राणायामः १२.

* * * *

अस्य श्रीलक्ष्मीसूक्तमन्त्रस्य श्रीः ऋषिः, त्रिष्टुप् छन्दः, अंभृणी-(ञ्जिनी)नामिका श्रीर्देवता ; द्वितियायाः अहं सोममोहनसमिति ऋचः जगती छन्दः, लक्ष्मीप्रेरणया लक्ष्मीप्रीत्यर्थे लक्ष्मीसूक्तमहामन्त्रजपे वियोगः ।

End :

परो दिवा पर एना पृथिव्यै तावती महिमा संबभूव। उपसंहारः पूर्ववत् ॥

No. 7116. लक्ष्मीस्तोत्रमन्त्रः.
LAKṢMĪSTŌTRAMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 4*b* of the MS. described under No. 7103.

Complete.

In praise of the goddess Mahālakṣmī, conceived as the primal cause of all things.

Beginning:

अस्य श्रीमहालक्ष्मीस्तोत्रमन्त्रस्य भार्गव ऋषिः, अनुष्टुप् छन्दः, आद्यादिश्रीमहालक्ष्मीर्देवता ; श्रीं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, आद्यादिश्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं श्रीं ह्रीं क्लीं सौं सौं ऐं क्लीं वन्दे लक्ष्मीम् ॥

No. 7117. लक्ष्मीहृदयस्तोत्रमन्त्रः.
LAKṢMĪHṚDAYASTŌTRAMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 4*a* of the MS. described under No. 7103.

Complete.

Similar to the above

Beginning:

अस्य श्रीमदथर्वणश्रीमदाद्यादिश्रीमहालक्ष्मीहृदयस्तोत्रमहामन्त्रस्य भार्गव ऋषिः, नाना छन्दांसि, श्रीमदथर्वणश्रीमदाद्यादिश्रीविजयमहालक्ष्मीर्देवता ; श्रीं बीजं, ह्रीं शक्तिः, ऐं कीलकं, श्रीमदाद्यादिश्रीविजयमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं इं ईं उं ऊं श्रीं स्वाहा । ओं श्रीं ह्रीं ऐं महालक्ष्मि कमलधारिणि श्रीं वषट् स्वाहा ॥

Colophon:

इति महालक्ष्मीसप्तदशाक्षरी विद्या ॥

No. **7118.** लक्ष्मीहृदयस्तोत्रमन्त्रः.

LAKṢMĪHṚDAYASTŌTRAMANTRAḤ.

Pages, 23. Lines, 6 on a page.

Begins on fol. 7*b* of the MS. described under No. 6487

Complete.

Similar to the above.

Beginning:

अस्य श्रीआद्यादिश्रीमहालक्ष्मीहृदयस्तोत्रमन्त्रस्य भार्गव ऋषिः शिरसि, अनुष्टुप् छन्दः नानाछन्दांसि मुखे, आद्यादिश्रीमहालक्ष्मीर्देवता हृदये ; ओं श्रीं बीजं गुदे, ओं ह्रीं शक्तिः आधारे, ओं ऐं कीलकं पादयोः, यजमानस्य अलक्ष्मीपरिहारार्थमाद्यादिश्रीमहालक्ष्मीहृदयस्तोत्रमन्त्रजपं करिष्ये ।

End:

(श्रीं) ध्याये त्वां प्रहसितमुखीं कोटिबा(ला)र्कभासां
विद्युद्वर्णाम्बर(वर)धरां भूषणाढ्यां सुशोभाम् ।
बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रं
भर्त्रा युक्तं मुहुरभय[प्र]दां मह्यमप्य(स्त्व)च्युतश्रीः ॥

Colophon:

इति श्रीलक्ष्मीहृदयस्तोत्रं सम्पूर्णम् ॥

No. **7119.** लक्ष्मीहृदयस्तोत्रमन्त्रः.

LAKṢMĪHṚDAYASTŌTRAMANTRAḤ.

Page, 1. Lines, 14 on a page.

Begins on fol. 104*a* of the MS. described under No. 5673, wherein it is wrongly stated as beginning on fol. 104*b*

Complete.

Similar to the above.

Beginning:

अस्य श्रीआद्यादिश्रीमहालक्ष्मीहृदयस्तोत्रमहामन्त्रस्य भार्गव ऋषिः, अनुष्टुबादिनानाछन्दांसि, आद्यादिश्रीमहालक्ष्मीनारायणो देवता ; ऐं श्री

बीजं, ओं ह्रीं शक्तिः, ओं ऐं कीलकं, मम अलक्ष्मीपरिहारार्थे आ-
द्यादिश्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे श्रीमहालक्ष्मीप्रीत्यर्थे जपे विनियोगः ।

End :

अथ मनुः—

ओं श्रीं ह्रीं ऐं सौः क्लीं महालक्ष्मि कमलधारिणि सिंहवाहिनि हं
स स्वाहा ॥

एतल्लक्ष्मीसप्तदशार्णविद्या अनेन व्यापकन्यासं कुर्यात् ॥

No 7120. लक्ष्मीहृदयस्तोत्रमन्त्रः.

LAKṢMĪHṚDAYASTŌTRAMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 42*a* of the MS. described under No. 5686

Complete.

Similar to the above.

Beginning :

अस्य श्रीमहालक्ष्मीहृदयस्तोत्रमन्त्रस्य भगवान् भार्गव ऋषिः,
अनुष्टुप् छन्दः, श्रीआद्यादिश्रीमहालक्ष्मीजगन्माता श्रीमहापरमेश्वरी
देवता ; श्रीं बीजं, ह्रीं शक्तिः, ऐं कीलकं, श्रीमहालक्ष्मीजगन्मातृ-
श्रीमहापरमेश्वरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

ओं श्रीं ह्रीं ऐं महालक्ष्मि कमलधारिणि स्वाहा ॥

Colophon :

इति महालक्ष्मीसप्तदशाक्षरी विद्या ॥

No 7121. लक्ष्मीहृदयस्तोत्रमन्त्रः.

LAKṢMĪHṚDAYASTŌTRAMANTRAḤ.

Pages, 3. Lines, 7 on a page.

Begins on fol. 15*a* of the MS. described under No. 408.

Complete.

Similar to the above

Beginning :

अस्य म्रा(श्री)लक्ष्मीहृदयस्तोत्रमन्त्रस्य भगवान् ऋषिः, अनुष्टुप् छन्दः, लक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मीः त्रिलोकीश्वरी
मा क्षीराब्धिसुता विरिञ्चिजननी विद्या सरोजात्मिका ।
सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादश
प्रातश्शुद्धतराः पठन्ति सततं सर्वं लभन्ते शुभम् ॥

Colophon :

इति श्रीलक्ष्मीहृदयस्तोत्रं सम्पूर्णम् ॥

No. **7122.** लक्ष्मीहृदयस्तोत्रमन्त्रः

LAKṢMĪHṚDAYASTŌTRAMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 92*a* of the MS described under No. 204.

Complete.

Similar to the above.

Beginning :

अस्य श्रीआद्यादिश्रीमहालक्ष्मीहृदयस्तोत्रमन्त्रस्य भार्गव ऋषिः, अनुष्टुप् छन्दः, आद्यादिश्रीमहालक्ष्मीर्देवता ; श्रीं बीजं, ह्रीं शक्तिः, ऐं कीलकं, ममाद्यादिमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः।

End :

मन्त्रः—

ओं श्रीं ह्रीं क्लीं ऐं ऐं क्लीं ह्रीं श्रीं ओं ॥

No **7123.** लक्ष्मीहृदयस्तोत्रमालामन्त्रः.

LAKṢMĪHṚDAYASTŌTRAMĀLĀMANTRAḤ

Pages, 3. Lines, 14 on a page.

Begins on fol. 104*a* of the MS. described under No **5673**, wherein this Mantra has been omitted to be included in the list of other works given therein.

Complete.

Similar to the above.

Beginning:

आद्यादिश्रीमहालक्ष्मीहृदयस्तोत्रमालामन्त्रस्य शिरसि, भार्गव ऋषिः इति ललाटे, अनुष्टुबादिनानाछन्दांसि इति मुखे, आद्यादिश्रीमहालक्ष्मीः नारायणो देवता इति नेत्रयोः, श्रीं बीजाय नमः हृदये, ह्रीं शक्त्यै नमः गुह्ये, ऐं कीलकाय नमः पादयोः,

* * * *

ओं ऐं अस्त्राय फट्, भूर्भुवस्सुवरोम्—इति दिग्बन्धः।

End:

मालामन्त्रः—

ओं श्रीं ह्रीं ऐं महालक्ष्मि कमलधारिणि हं स्वाहा॥

No. 7124. लघुमातङ्गीमन्त्रः.
LAGHUMĀTAṄGĪMANTRAḤ.

Page, 1. **Lines**, 5 on a page.

Begins on fol. 87*a* of the MS. described under No. 5566.

Complete.

This Mantra is addressed to the goddess Laghu-Mātaṅgī; and its repetition is believed to have the power to enable one to accomplish one's desires as quickly as possible.

Beginning:

अस्य श्रीलघुमातङ्गीमन्त्रस्य मतङ्ग ऋषिः, अत्यनुष्टुप् छन्दः, लघुश्यामा देवता, ऐं बीजं, नमश्शक्तिः, सर्ववशङ्करीति कीलकं, मम इष्टकाम्यार्थसिद्ध्यर्थे विनियोगः। षडङ्गन्यासः।

End:

ऐं नमः उच्छिष्टचण्डालि मातङ्गि सर्ववशङ्करि स्वाहा॥

कलौ कलिजिते काले साधकस्य प्रसीदति।
लघुशीघ्रेण तेनेयं लघुश्यामेति गीयते॥
मन्त्रराजमिदं साक्षाल्लब्ध्वा कुलगुरोर्मुखात्।

उच्छिष्टः प्रजपेन्मन्त्रं लक्षमेकमनाकुलः ॥
शून्यागारे श्मशाने वा तदेकतरुमुस्थले ।
निशादौ स्वगृहे वापि मदिरामोदमानसः ॥

No. **7125.** लघुमातङ्गीमन्त्रः.
LAGHUMĀTAṄGĪMANTRAḤ.

Pages, 2. Lines, 19 on a page.

Begins on fol. 275*a* of the MS. described under **No. 5477,** wherein this Mantra is found in the Mantramālikā **273*a*** given therein in the list of other works.

Complete.

Same as the above.

Colophon:

इति लघुमातङ्गी ॥

No. **7126.** लघुमातङ्गीमन्त्रः.
LAGHUMĀTAṄGĪMANTRAḤ.

Pages, 2. Lines, 27 on a page.

Begins on fol 231*a* of the MS. described **under No.** 581, wherein this Mantra is found in the Mantramālikā 229*a* given therein in the list of other works

Complete.

Same as the above.

No. **7127.** लघुमातङ्गीमन्त्रः.
LAGHUMĀTAṄGĪMANTRAḤ.

Pages, 2. Lines, 4 on a page.

Begins on fol. 7*b* of the MS. described under No. 5686.

Complete

Similar to the above.

Beginning:

अस्य श्रीलघुमातङ्गेश्वरीमहामन्त्रस्य मतङ्गभगवानृषिः, अनुष्टुप् छन्दः, श्रीलघुमातङ्गेश्वरी देवता; ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, मम श्रीलघुमातङ्गेश्वरीमहामन्त्रदेवताप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः ।
उच्छिष्टचण्डालि मातङ्गि सर्वजनवशङ्करि स्वाहा ॥

No. 7128. लघुमातङ्गीमन्त्रः.
LAGHUMĀTAṄGĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 229*b* of the MS. described under No. 124, wherein this Mantra is found in the Ṣaḍāmnāyamantra 228*b* given therein in the list of other works.

Complete.
Similar to the above.

Beginning:

अस्य श्रीलघुमातङ्गीश्वरीमहामन्त्रस्य मतङ्गभैरव ऋषिः, पङ्क्तिश्छन्दः; लघुमातङ्गीश्वरी देवता; ऐं बीजं, नमश्शक्तिः, स्वाहेति कीलकं, लघुमातङ्गीश्वरीप्र—गः ।

End:

ऐं नम उच्छिष्टचण्डालि मातङ्गि सर्ववशङ्करि स्वहा । लघुमातङ्गीश्वरीदिव्यश्रीपादुकां—मि ॥

No. 7129. लघुमातङ्गीमन्त्रः.
LAGHUMĀTAṄGĪMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 37*a* of the MS. described under No. 6414.

Complete.

Similar to the above.

Beginning:

अस्य श्रीलघुमातङ्गीमन्त्रस्य मतङ्ग ऋषिः, दैवी गायत्री छन्दः, ऐं बीजं, क्लीं शक्तिः, मम भोगमोक्षार्थे जपे विनियोगः ।

End:

मनुः—
क्लीं ऐं उच्छिष्टचण्डालि लघुमातङ्गि सर्ववश्यङ्करि स्वाहा ॥

No. **7130.** लघुवाराहीमन्त्रः.

LAGHUVĀRĀHĪMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 88*b* of the MS. described under No. 5566, wherein it has been wrongly given as beginning on fol. 88*a*.

Complete.

The repetition of this Mantra, which is addressed to the goddess Vārāhī (one of the seven goddesses recognised by the name Saptamātṛs), is considered to be efficacious in causing the destruction of one's enemies.

Beginning:

अस्य श्रीलघुवाराहीमन्त्रस्य त्रिलोचन ऋषिः, त्रिष्टुप् छन्दः, लघुवाराही देवता; ल्कं बीजं, नमश्शक्तिः, ल्कं कीलकं, मम शत्रुक्षयार्थे जपे विनियोगः ।

End:

मन्त्रः—

ल्कं वाराहि लुं उन्मत्तभैरवि पादुकाभ्यां नमः ।

पुरश्चरणं लघोः लक्षं, बृहतः लक्षं, दीपस्य लक्षं, जिह्वालक्षं, अस्त्रस्य दश, होमतर्पणानि तिलः दशांशः ॥

No. **7131.** लघुवाराहीमन्त्रः.

LAGHUVĀRĀHĪMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 233*a* of the MS. described under No. 581, wherein this Mantra is found in the Mantramālikā 229*a* given therein in the list of other works.

Complete.

Same as the above.

No. **7132.** लघुश्यामलामन्त्रः.

LAGHUŚYĀMALĀMANTRAḤ.

Pages, 2. Lines, 16 on a page.

Begins on fol. 194*a* of the MS. described under No. 424, wherein it is apparently wrongly printed as beginning on fol. 114*a*.

Complete.

This Mantra is addressed to Śyāmalā who appears to be the same as the goddess Mātaṅgī. She is called Śyāmalā because she is conceived as possessing a dark complexion.

Beginning :

अस्य श्रीलघुश्यामलामहामन्त्रस्य मतङ्गभैरव ऋषिः, पङ्क्तिश्छदः, लघुश्यामला देवता; ऐं बीजं, नमः शक्तिः, स्वाहा कीलकं, लघुश्यामला-प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

मनुः—

ऐं ईं ओं शुद्धविद्याम्बाश्रीपादुकां मानसोपचारसम्पूर्णमुद्रां प्रदर्श्य ॥

No. **7133.** लघुश्यामलामन्त्रः.

LAGHUŚYĀMALĀMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 4*a* of the MS. described under No. 673, wherein it is found in the Ṣaḍāmnāyamantra fol 1*a* given therein in the list of other works.

Incomplete.

Similar to the above.

Beginning :

अस्य श्रीलघुश्यामलामहामन्त्रस्य मतङ्गभैरव ऋषिः, अनुष्टुप् छन्दः, लघुश्यामला देवता ; ऐं बीजं, नमश्शक्तिः, स्वाहा कीलकं, मम लघुश्यामलाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

उच्छिष्टचण्डालि मातङ्गि सर्वजनवशङ्करि स्वाहा । लघुश्यामला-श्रीपा . . . नमः ॥

No. **7134.** लघुश्यामलामन्त्रः.

LAGHUŚYĀMALĀMANTRAḤ.

Pages, 2. Lines, 4 on a page.

Begins on fol. 29*a* of the MS. described under No. 2848, wherein it is found in the Pūrvāmnāyamantramālikā 16*a* given therein in the list of other works.

Complete.

Similar to the above.

Beginning :

अस्य श्रीलघुश्यामलाम्बामन्त्रस्य मतङ्ग ऋषिः, पङ्क्तिश्छन्दः, लघुश्यामलाम्बा देवता; ऐं बीजं, नमश्शक्तिः, क्लीं कलिकं, विनियोगः।

End:

उच्छिष्टचण्डालि मातङ्गि मम सर्वजनवशङ्करि ठ ठ ठ स्वाहा।

* * * *

सद्योजातं भवोद्भवाय नमः—आकाशरूपाय सृष्टिकर्त्रे ब्रह्मणे नमः॥

Colophon :

इति पूर्वाम्नायः॥

No. **7135.** लघुश्यामलामन्त्रः.

LAGHUŚYĀMALĀMANTRAḤ.

Pages, 3. Lines, 7 on a page.

Begins on fol. 4*b* of the MS. described under No. 6514.

Complete.

Similar to the above.

Beginning :

अस्य श्रीलघुश्यामलामहामन्त्रस्य मतङ्ग ऋषिः, गायत्री छन्दः, लघुश्यामला देवता; ऐं बीजं, नमश्शक्तिः, स्वाहा कीलकं, मम लघुश्यामलाप्रसादसिद्ध्यर्थे जपे विनियोगः।

No. 7136. लघुश्यामलामातङ्गेश्वरीमन्त्रः.

LAGHUŚYĀMALĀMĀTAṄGĒŚVARĪMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 12*a* of the MS. described under No. 2037.

Complete.

Similar to the above.

Beginning:

अस्य श्रीलघुश्यामलामातङ्गेश्वरीमहामन्त्रस्य मदन ऋषिः, निचृद्गायत्री छन्दः, लघुश्यामला देवता, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, मम लघुश्यामलाप्रसादसिद्ध्यर्थे जपे विनियोगः।

End:

ओन्नम उच्छिष्टचण्डालि मातङ्गि सर्वजनवशङ्करि स्वाहा ॥

No. 7137. लघुश्यामलाम्बिकामन्त्रः.

LAGHUŚYĀMALĀMBIKĀMANTRAḤ.

Pages, 2. Lines, 14 on a page.

Begins on fol. 12*a* of the MS. described under No. 5673, wherein it is found in the Āmnāyamantramālikā 1*a* given therein in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीलघुश्यामलाम्बिकामहामन्त्रस्य मतङ्गानन्दभगवानृषिः, अनुष्टुप् छन्दः, श्रीलघुमातङ्गीश्वरी देवता; ऐं नमः बीजं, उच्छिष्टेति शक्तिः, स्वाहेति कीलकं, मम श्रीलघुश्यामलाम्बिकाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—

ओं नम उच्छिष्टचण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । श्रीलघुमातङ्गीश्वरीश्री ॥

No. **7138.** ललिताकवचः.

LALITĀKAVACAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 50*a* of the MS. described under No. 5858.

Complete.

Addressed to the goddess Lalitā, who is the same as Śakti, for securing her favour and protection.

Beginning :

अस्य श्रीललिताकवचस्तवरत्नमन्त्रस्य आनन्दभैरव ऋषिः, अमृत-विराट् छन्दः, श्रीमहात्रिपुरसुन्दरी ललिता पराम्बा देवता; ऐं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, मम श्रीललिताम्बाप्रसादसिद्ध्यर्थे कवचस्तव-रत्नमन्त्रजपे विनियोगः ! . . . .

ककारः पातु शीर्षे मे एकारः पातु फालकम् ।
ईकारश्चक्षुषी पातु श्रोत्रे रक्षेल्लकारकः ॥

* * * *

ललिता पातु शिरो मे ललाटमम्बा च मधुमतीरूपा ।
भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् ॥

End :

मधुरस्मितां मदारुणनयनां मातङ्गकुम्भवक्षोजाम् ।
चन्द्रावतंसिनीं त्वां सततं पश्यन्ति सुकृतिनः केचित् ॥
ललितायास्स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः ।
अनुदिनमनुचिन्तयतां फलानि वक्तुं प्रगल्भते स शिवः ॥
पूजाहोमस्तर्पणं स्यान्मन्त्रशक्त्या प्रभावतः ।
पुष्पाज्यतोयाभावे तु जपमात्रेण सिध्यति ॥

Colophon :

इति श्रीललितार्याकवचस्तोत्ररत्नं संपूर्णम् ॥

No. 7139. लवनपञ्चाक्षरमन्त्रः.

LAVANAPAÑCĀKṢARAMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 3*a* of the MS. described under No. 2886.

Complete.

The proper repetition of this Mantra is believed to have the power, as implied in its name, to free one from the bondage of Saṁsāra and to secure salvation. The five-syllabled Mantra is not given in the manuscript.

Beginning :

लवनपञ्चाक्षरमहामन्त्रस्य ब्रह्मविष्णुरुद्रेश्वरसदाशिव(ा) ऋषिः(षयः), गायत्र्युष्णिगनुष्टुप् [छन्दः] बृहती पङ्क्तिश्छन्दांसि, विराड्रूपो देवता ; लं बीजं, रं शक्तिः, हं कीलकं, लवनपञ्चाक्षरसिद्ध्यर्थे जपे विनि-योगः ।

End:

आकाशाच्च विशुद्धवृत्तसदृशं यद्ब्रह्मरन्ध्रास्थितं
तन्नादेन सदाशिवेन सहितं शान्तं हकारान्वितम् ।
प्राणं तत्र विलीनपञ्चघटिकाचि(श्चि)त्तान्वितं धारयेत्
एषा मोक्षकवाटभेदनकरी प्रोक्ता नभोधारिणी ॥

No. 7140. लीलादण्डधरगोपालमन्त्रः.

LĪLĀDAṆḌADHARAGŌPĀLAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 56*b* of the MS. described under No. 5865.

Complete.

This Mantra is addressed to Kṛṣṇa conceived as a cow-herd having in his hand a playing stick. The word Līlādaṇḍadhara may also convey the idea that Kṛṣṇa inflicts punishment on the wicked by way of sport.

Beginning :

अस्य श्रीलीलादण्डधरगोपालमन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, लीलादण्डधरगोपालो देवता; आं बीजं, ह्रीं शक्तिः, क्रों कीलकं, श्रीलीलादण्डधरगोपालप्रीत्यर्थे जपे विनियोगः ।

End :

मनुः—

आं ह्रीं क्रों आं लीलादण्डधरगोपीजनवल्लभाय स्वाहा ॥

No. 7141. लोकपालमन्त्रः.

LŌKAPĀLAMANTRAḤ.

Page, 1. Lines, 18 on a page

Begins on fol. 44*b* of the MS. described under No. 2886, wherein it is found in the Ākāśabhairavakalpa 38*a* given therein in the list of other works.

Complete, as found in the 36th Adhyāya of Ākāśabhairavakalpa.

This Mantra is addressed to the eight guardians of the quarters, viz., Indra, Agni, Yama, Nirṛti, Varuṇa, Vāyu, Kubēra, and Īśa.

Beginning :

मन्त्रस्य लोकपालानां घोररुद्र ऋषिस्तथा ।
अनुष्टुबुष्णिक् त्रिष्टुप् च कृतिर्गायत्रमेव च ॥
जगती बृहती पङ्क्तिः क्रमाच्छन्दोऽभिधीयते ।
देवतास्त्वयि दिक्पालास्तथा बीजानि शाम्भवि ॥

End :

ओं नमो भगवते शां ईशानाय त्रिशूलहस्ताय विद्याधिपतये वृषभवाहनाय सशक्तिकाय सपरिवाराय हुं फट् स्वाहा—इतीशानः ॥

* * *

मूलं विनानेन दिशां पतीनां मन्त्रप्रयोगेण सपल्लवेन ।
कुर्यान्मनीषी सततं वरेण्यकर्मस्वशेषेषु यथाक्रमेण ॥

Colophon :

इत्याकाशभैरवकल्पे दिक्पालमन्त्रं नाम षट्त्रिंशोऽध्यायः ॥

No. 7142. लोपामुद्रामन्त्रः.
LŌPĀMUDRĀMANTRAḤ.

Pages, 2 Lines, 14 on a page.

Begins on fol. 18*b* of the MS. described under No. 5673, wherein it is found in the Āmnāyamantramālikā 1*a* given therein in the list of other works.

Complete.

Lōpāmudrā is the wife of the sage Agastya. She has been deified as a manifestation of Aṁbā; and the repetition of this Mantra is intended to propitiate her.

Beginning :

अस्य श्रीलोपामुद्राम्बामन्त्रस्य नित्यानन्दभैरव ऋषिः, गायत्री छन्दः, श्रीलोपामुद्राम्बा देवता; ह्रीं बीजं, ऐं शक्तिः, क्लीं कीलकं, मम श्रीलोपामुद्राम्बाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

मनुः—

ह स क ल ह्रीं ह स क ल ह्रीं स क ल ह्रीं श्रीलोपा-मुद्राम्बाश्री ॥

No. 7143. लोपामुद्रामन्त्रः.
LŌPĀMUDRĀMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 231*a* of the MS. described under No. 124, wherein it is found in the Ṣaḍāmnāyamantra 228*b* given in the list of other works.

Complete.

Same as the above.

No. 7144. लोपामुद्रामन्त्रः.
LŌPĀMUDRĀMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 5*b* of the MS described under No. 673, wherein it is found in the Ṣaḍamnāya 1*a* given therein in the list of other works.

Complete.

Same as the above.

No. **7145.** वटपत्रशयनगोपालमन्त्रः.

VAṬAPATRAŚAYANAGÔPĀLAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 57*b* of the MS. described under No. 5885.

Complete.

The repetition of this Mantra is considered to have the power to secure the grace of Kṛṣṇa conceived as a little baby lying down on a banyan leaf.

Beginning:

अस्य श्रीवटपत्रशयनगोपालमन्त्रस्य नारद ऋषिः, जगती छन्दः, श्रीवटपत्रशयनगोपालो देवता; ओं बीजं, नमश्शक्तिः, श्रीवटपत्रशयनगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

ओं नमो भगवते वासुदेवाय स्वाहा ॥

No. **7146.** वटमूलदक्षिणामूर्तिमन्त्रः.

VAṬAMŪLADAKṢIṆĀMŪRTIMANTRAḤ.

Pages, 4. Lines, 6 on a page.

Begins on fol. 24*a* of the MS. described under No. 5928.

Complete.

This Mantra is addressed to Dakṣiṇāmūrti (Śiva) conceived as resting at the foot of a banyan tree; and its repetition is intended to secure the favour of Śiva.

Beginning:

अस्य श्रीवटमूलदक्षिणामूर्तिमहामन्त्रस्य शुक ऋषिः, अनुष्टुप् छन्दः, वटमूलदक्षिणामूर्तिः परमात्मा देवता; ह्रीं बीजं, नमश्शक्तिः, ओं कीलकं, मम श्रीदक्षिणामूर्तिप्रीत्यर्थे जपे विनियोगः ।

End:

ओं ह्रीं दक्षिणामूर्तये तुभ्यं वटमूलनिवासिने । ध्यानैकनिरताङ्गाय महारुद्राय शम्भवे । ह्रीं ओं । पञ्चपूजां च कुर्यात् । वटमूलदक्षिणामूर्तिपादुकां पूजयामि स्वाहा ॥

No. 7147. वटयक्षिणिमन्त्रः.
VAṬAYAKṢIṆĪMANTRAḤ.

Pages, 2. Lines, 18 on a page

Begins on fol. 297*a* of the MS. described under No. 5477, wherein this Mantra is found in the Mantramālikā 273*a* given therein in the list of other works.

Complete.

This Mantra is addressed to Yakṣiṇī, who is popularly supposed to be residing on a banyan tree.

Beginning :

ऋष्यादिकं पूर्ववत् । मन्त्रः—

ब्लीं कालकण्ठिके ठ ठ ठ स्वाहा । लक्षजपं कुर्यात् ।

End :

तत्तत्कार्यं विचिन्तयेत् । पूर्वस्थाने जपहोमं कुर्यात्—इति ॥

No. 7148. वटुकत्रयमन्त्रः.
VAṬUKATRAYAMANTRAḤ.

Pages, 2. Lines, 17 on a page.

Begins on fol. 4*a* of the MS. described under No. 5673, wherein this Mantra is found in the Āmnāyamantramālikā 1*a* given therein in the list of other works

Complete.

The repetition of this Mantra is believed to have the power to please the three attendants of the goddess Śakti known as Vaṭukas. The names of these Vaṭukas are (1) Skandavaṭuka, (2) Citravaṭuka and (3) Viriñcivaṭuka.

Beginning :

अस्य श्रीवटुकत्रयमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः, गायत्री छन्दः, वटुकत्रया(य्य)धिदेवता, श ष स ह अभिभसः इति बीजं, सरस्वती महालक्ष्मीः गौरीति शक्तयः, ऐं ह्रीं श्रीं इति कीलकं, मम वटुकत्रयप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—

श्रीं ह्रीं सौः हुं फट् स्कन्दवटुकश्री ६, चित्रवटुकश्री ६, विरिञ्चिवटुकश्री ६ ॥

No. **7149.** वटुकत्रयमन्त्रः.

VAṬUKATRAYAMANTRAḤ.

Pages, 2. Lines, 4 on a page.

Begins on fol. 20*b* of the MS. described under No. 2848

Complete.

Same as the above

No. **7150.** वटुकत्रयमन्त्रः.

VAṬUKATRAYAMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 231*a* of the MS. described under No. 124, wherein this Mantra is included in the Saḍāmnāyamantra 228*b* given therein in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीवटुकत्रयमन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः, ऋग्यजुस्सामाथर्वाणश्छन्दांसि, वटुकत्रयो देवता; सरस्वतीलक्ष्मीगौर्यश्शक्तयः, ऐं श्रीं ह्रीं कीलकं, वटुकत्रयप्र—गः ।

End:

ह्रीं श्रीं हुं फट् । स्कन्दवटुकदिव्य, चित्रवटुकदिव्य, विरिञ्चिवटुकदि—मः ॥

No. **7151.** वटुकभैरवदिग्बन्धनमन्त्रः.

VAṬUKABHAIRAVADIGBANDHANAMANTRAḤ

Pages, 11. Lines, 16 on a page.

Begins on fol. 281*b* of the MS. described under No. 424, wherein this Mantra has been omitted to be included in the list of other works given therein.

Complete.

The repetition of this Mantra which is addressed to Vaṭukabhairava who is a manifestation of Bhairava is believed to have the power to protect one from the dangers that may come from various quarters.

Beginning:

ओं जृम्भिणीं स्तम्भिनीं मोहिनीं पूर्वद्वारं बन्धाबान्धि, हम्र्यों अग्निद्वारं बन्धाबान्धि, ड्रूं डैं यमद्वारं बन्धाबन्धि ।

End:

ओं ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ।

दिगम्बराय विद्महे शूलहस्ताय धीमहि । तन्नः कालभैरवः प्रचोदयात् । उ त्वा मदन्तु स्तोमाः । कृणुष्व राधोऽद्रिवः । अव ब्रह्म द्विषो जहि । ओं नमो भगवते रुद्राय ॥

No. 7152. वटुकभैरवमन्त्रः.

VAṬUKABHAIRAVAMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 11*a* of the MS. described under No. 5828.

Complete.

This Mantra is also addressed to Vaṭukabhairava. Its repetition is intended to enable one to accomplish one's desires.

Beginning:

अस्य श्रीवटुकभैरवमहामन्त्रस्य भैरव ऋषिः, अनुष्टुप् छन्दः, वटुकभैरवो देवता; ओं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, मम इष्टकाम्यार्थसिद्ध्यर्थे जपे विनियोगः ।

End:

क्रों क्ष्यों महाभैरव बन्धय बन्धय पोट्ठ पोट्ठ हुं फट् स्वाहा ॥

No. 7153. वटुकभैरवमन्त्रः.
VATUKABHAIRAVAMANTRAH.

Pages, 2. Lines, 16 on a page.

Begins on fol. 280*b* of the MS. described under No. 424.

Incomplete.

The repetition of this Mantra which is addressed to Vaṭuka-bhairava is believed to have the power to enable one to overcome all dangers.

Beginning :

अस्य श्रीआपदुद्धारकवटुकभैरवमन्त्रस्य पुलस्त्य ऋषिः, गायत्री छन्दः, श्रीआपदुद्धारकवटुकभैरवो देवता; वं बीजं, नमश्शक्तिः, वटुकायेति कीलकं, मम आपदुद्धारकवटुकभैरवप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

शङ्खचक्रवराभीतिहस्तपद्म[ ]युतोऽव्ययः ।
नीलाञ्जनसमाभासः पातालं पात्वनारव(तम्) ॥
अनुक्तापि दिशिहेति साळुवा(?)

No. 7154. वटुकभैरवमन्त्रः.
VATUKABHAIRAVAMANTRAH.

Page, 1. Lines, 10 on a page.

Begins on fol. 230*b* of the MS. described under No. 124, wherein this Mantra is found in the Ṣaḍāmnāyamantra 228*b* given therein in the list of other works.

Complete.

Similar to the above.

Beginning :

अस्य श्रीवटुकभैरवमहामन्त्रस्य स्कन्द ऋषिः, अनुष्टुप् छन्दः, आपदुद्धारणवटुकभैरवो देवता; वं बीजं, ह्रीं शक्तिः, क्रों कीलकं, आपदुद्धारणवटुकभैरवप्र—गः ।

End :

ओं ह्रीं वं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं ओं फट् स्वाहा । आपदुद्धारणवटुकभैरवादिव्य——मः ॥

No. **7155.** **वनदुर्गादिग्बन्धनमन्त्रः.**

VANADURGĀDIGBANDHANAMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 102*b* of the MS. described under No. 124, wherein it is given as Mahāvidyāvanadurgā.

Complete.

The repetition of this Mantra, which is addressed to Vanadurgā i.e., Durgā conceived as residing in the forest, is believed to have the power to protect one from all the dangers that may come from the various quarters.

Beginning :

ओं नमश्चण्डिकायै नमः । ओं ऐं ह्रीं श्रीं जम्भिनि मोहिनि स्तम्भिनि पूर्वद्वारं बन्ध बन्ध, ओं अं ह्रुमर्म्यूं रं अग्निद्वारं बन्ध बन्ध ओं यं यमद्वारं बन्ध बन्ध ।

End :

ओं ह्रीं दुं क्षं शिवं कुरु कुरु ह्रां ह्रीं ह्रूं हुं फट् स्वाहा । ओं आं ईं ह्रौं स्वाहा ॥

No. **7156.** **वनदुर्गादिग्बन्धनमन्त्रः.**

VANADURGĀDIGBANDHANAMANTRAḤ.

Substance, palm-leaf. Size, 15½ × 1⅜ inches. Pages, 2. Lines, 7 on a page. Character, Telugu. Condition, good. Appearance, old.

Begins on fol. 12*b*. The other works herein are Sūryōpāsanavidhi 1*a*, Śanaiścarastōtra 7*a*, Aśvatthanārāyaṇastōtra 8*a*, Ādityapūjāyantra 9*b*, Vanadurgāpārāyaṇa 11*a*, Vanadurgāmantra 11*b*, Vanadurgāmahāvidyāmālāmantra 13*a*, Sūryanamaskāra 42*a*.

Complete.

Same as the above.

No. 7157. वनदुर्गादिग्बन्धनमन्त्रः.

VANADURGĀDIGBANDHANAMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 57*a* of the MS. described under No. 5639, wherein it is given as Caṇḍikāmantra.

Complete.

Similar to the above.

Beginning:

ओं नमश्चण्डिकायै नमः, ओं नमश्चण्डिकायै नमः, ओं नमश्चण्डिकायै नमः । जम्भिनी स्तम्भिनी मोहिनी पूर्वद्वारं बन्धाबन्धि, ह्म्यौं अग्निद्वारं बन्धाबन्धि . . . . यमद्वारं बन्धाबन्धि, न्यां निरृतिद्वारं बन्धाबन्धि ।

End:

दुर्गाहनुमन्तगणेश्वरादिसर्वाङ्गसर्वग्रहं बन्धाबन्धि सर्वकिल्बिषक्षुद्रोपद्रवं छिन्धि छिन्धि भिन्धि खे खे हुं फट् फट् स्वाहा ॥

No. 7158. वनदुर्गादिग्बन्धनमन्त्रः.

VANADURGĀDIGBANDHANAMANTRAḤ.

Page, 1. Lines, 20 on a page.

Begins on fol. 25*a* of the MS. described under No. 5574, wherein it is found in the Vandurgāmahāvidyā given therein in the list of other works.

Complete.

Same as the above.

No. 7159. वनदुर्गादिग्बन्धनमन्त्रः.

VANADURGĀDIGBANDHANAMANTRAḤ.

Pages, 2. Lines, 4 on a page.

Begins on fol. 175*b* of the MS. described under No. 29, wherein it has been omitted to be given in the list of other works therein contained.

Complete.

Same as the above.

No. 7160. वनदुर्गामन्त्रः.
VANADURGĀMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 235*b* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229 given therein in the list of other works

Complete.

The repetition of this Mantra which is also addressed to Vanadurgā is intended to enable one to accomplish one's desires. The Mantra is coupled with a prayer in the end addressed to the goddess to remove all fears.

Beginning:

अस्य श्रीवनदुर्गामन्त्रस्य आरण्यक ऋषिः, अत्यनुष्टुप् छन्दः, श्रीवनदुर्गा देवता; दुं बीजं, स्वाहा शक्तिः, हुं कीलकं, ममेष्टकाम्यार्थसिद्ध्यर्थे विनियोगः ।

End:

मन्त्रः—

ओं दुं उत्तिष्ठ(पुरुषि)किं स्वपिषि भयं मे समुपस्थितं यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥

No. 7161. वनदुर्गामन्त्रः.
VANADURGĀMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 90*a* of the MS. described under No. 5536.

Complete.

Same as the above.

No. 7162. वनदुर्गामन्त्रः.
VANADURGĀMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol 277*b* of the MS. described under No. 5477, wherein it is found in the Mantramālikā 273*a* given therein in the list of other works.

Complete.

Same as the above.

No. **7163.** वनदुर्गामन्त्रः.

VANADURGĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 59*a* of the MS. described under No. 235, wherein it is given as Mahāvidyā in the list of other works.

Complete.

Similar to the above.

Beginning :

अस्य श्रीवनदुर्गामहामन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, अन्तर्यामिनारायणाकिरातरूपधर ईश्वरो देवता ; दुं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, मम वनदुर्गाप्रसादसिध्यर्थे जपे विनियोगः ।

End :

ओं ह्रीं श्रीं दुं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय शमय स्वाहा ॥

ओं नमश्चण्डिकायै नमः ॥

No. **7164.** वनदुर्गामन्त्रः.

VANADURGĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 21*a* of the MS. described under No. 5928.

Complete.

Similar to the above. Considered also to have the power to propitiate Dakṣiṇāmūrti or Śiva.

Beginning :

अस्य श्रीअरण्येश्वरवश्यश्रीवनदुर्गात्रिपुरसुन्दरीपरमेश्वरीस्तोत्रमहामन्त्रस्य अरण्येश्वर ऋषिः, अत्यनुष्टुप् छन्दः, अन्तर्यामिनारायणी किरातधरवनदुर्गा ईश्वरी देवता ; दुं बीजं, ह्रीं शक्तिः, क्रों, कीलकं, श्रीदाक्षिणामूर्तिप्रसादसिद्धयर्थे जपे विनियोगः ।

End :

तन्मे भगवति दुर्गे शमय स्वाहा । श्रीवनदुर्गादेवीश्रीपादुकां पूजयामि ॥

No. 7165. वनदुर्गामन्त्रः.
VANADURGĀMANTRAḤ.

Pages, 2. Lines, 9 on a page.

Begins on fol. 6*a* of the MS. described under No. 6548, wherein it is given as Vanadurgāmahāmantra in the list of other works.

Complete.

Similar to the above.

Beginning :

अस्य वनदुर्गामहामन्त्रस्य आरण्यकभगवान् ऋषिः, अनुष्टुप् छन्दः, वनदुर्गा परमेश्वरी देवता, दुं बीजं, स्वाहा शक्तिः, मम सर्वाभीष्टसिद्ध्यर्थे वनदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

मौलौ चन्द्रकलावती मनसि मे(च)श्रीकण्ठचिन्तावती
गाने दिव्यसुधावती करतले कल्याणवीणावती ।
कण्ठे हारलतावती कचभरे कादम्बमालावती
दृष्टौ पूर्णकृपावती दिशतु नश्श्रेयांसि सा पार्वती ॥
ओं वाराह्यै नमः, श्रीसरस्वत्यै नमः, अम्बिकायै नमः ॥

No. 7166. वनदुर्गामन्त्रः.
VĀNADURGĀMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 28*b* of the MS. described under No. 2424.

Complete.

Similar to the above.

Beginning :

हेमप्रख्यामिन्दुखण्डार्धमौलिं शङ्खारिष्टाभीतिहस्तां त्रिनेत्राम् ।
हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥

अस्य श्रीवनदुर्गापरमेश्वरीमहामन्त्रस्य अरण्य ऋषिः, अनुष्टुप् छन्दः, वनदुर्गा परमेश्वरी देवता; दुं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, वनदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥

No. **7167.** वनदुर्गामन्त्रः.

VANADURGĀMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol 56*a* of the MS. described under No. 5639.

Complete.

Similar to the above. The repetition of this Mantra is considered to have the power to promote one's health, wealth and prosperity.

Beginning :

शरदिन्दुविकासमन्दहासां स्फुरदिन्दीवरलोचनाभिरामाम् ।
अरविन्दसमानसुन्दरास्यामरविन्दासनसुन्दरीमुपासे ॥

* * * *

एवंगुणविशेषणविशिष्टायामस्यां तिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थं मम . . . वनदुर्गामहाविद्यापूजापारायणं करिष्ये—

अस्य श्रीवनदुर्गामहामन्त्रस्य अरण्येश्वर ऋषिः शिरसि, अनुष्टुप् छन्दः मुखे, अन्तर्यामिनारायणाकिरातरूपधरेश्वरी श्रीवनदुर्गा महात्रिपुरसुन्दरी देवता हृदि, दुं बीजं, ह्रीं शक्तिः, क्रों कीलकं, वनदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

श्रीं ह्रीं क्लीं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं . . अष्टाविंशतिवारं जपित्वा ।

सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः इति त्रिः ॥

No. 7168. वनदुर्गामहाविद्यापारायणम्.
VANADURGĀMAHĀVIDYĀPĀRĀYAṆAM.

Pages, 2. Lines, 8 on a page.

Begins on fol. 102*a* of the MS. described under No. 124; wherein it is given as Mahāvidyā

Complete.

This Mantra is addressed chiefly to Vanadurgā, although it contains also the Pāśupatāstramantra and Śarabhasāluva-gāyatrī-mantra. It is called Mahāvidyā and is intended to enable one to secure the favour of Vānadurgā.

Beginning:

वन्दे गुरुपदद्वन्द्वमवाङ्नसगोचरम् ॥
(म)
रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः ॥

* * * *

पूर्वोक्तैवङ्गुणविशेषणविशिष्टायां शुभतिथौ वनदुर्गामुद्दिश्य वनदुर्गाप्रीत्यर्थं महाविद्यापारायणं करिष्ये—

ओं ऐं ह्रीं श्रीं द्रां सङ्क्षोभणमुद्रायै नमः, ओं श्रीं ह्रीं द्रीं सम्मोहनमुद्रायै नमः ।

End:

ओं दुं ऐं श्रीं ह्रीं क्लीं दुं ओं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥

No. 7169. वनदुर्गामहाविद्यापारायणम्.
VANADURGĀMAHĀVIDYĀPĀRĀYAṆAM.

Pages, 3. Lines, 7 on a page.

Begins on fol. 11*a* of the MS. described under No 7156.

Complete.

Same as the above.

No. 7170. वनदुर्गामहाविद्यामन्त्रः.
VANADURGĀMAHĀVIDYĀMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 45*b* of the MS. described under No. 2886.

Complete.

Similar to the above.

Held also to be efficacious in causing harm to one's enemies in various ways.

Beginning:

अस्य वनदुर्गामहाविद्यामन्त्रराजस्तोत्रमहामन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, अन्तर्यामी नारायणः किरातरूपधर ईश्वरो देवता; दुं बीजं, स्वाहा शक्तिः, क्लीं कीलकं, मम प्रतिकूलकारिणो ये ये स्थानेषु स्थिताः, तेषां पशुपुत्रमित्रकलत्रसंहारणार्थे . . . . वनदुर्गामहाविद्याप्रीत्यर्थं वनदुर्गामहाविद्यामन्त्रजपं करिष्ये.

End:

ओं ह्रीं दुं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा॥ पञ्चपूजा ॥

No. 7171. वनदुर्गामहाविद्यामन्त्रः.
VANADURGĀMAHĀVIDYĀMANTRAḤ.

Pages, 4. Lines, 4 on a page.

Begins on fol. 174*a* of the MS. described under No. 29, wherein it is given under the name Vanadurgāstōtra.

Complete.

Similar to the above.

Beginning:

अस्य श्रीमहाविद्यावनदुर्गास्तोत्रमन्त्रराजस्य अरण्येश्वर ऋषिः, अत्यनुष्टुप् छन्दः, ह्रीं अन्तर्यामिनारायण[ः] किरातरूपधरेश्वरी वनदुर्गा देवता, ओं दुं बीजं, स्वाहा शक्तिः, ह्रीं कीलकं, श्रीमहाविद्यावनदुर्गादेवताप्रसादसिध्यर्थे जपे विनियोगः।

See under the previous number for the end

No. 7172. वनदुर्गामहाविद्यामन्त्रः.

VANADURGĀMAHĀVIDYĀMANTRAḤ.

Pages, 2. Lines, 20 on a page.

Begins on fol. 41*a* of the MS. described under No. 5574.

Complete.

Similar to the above.

Beginning:

श्रीनाथादिगुरुत्रयं गणपतिं दुर्गां वटुकां शिवमच्युतम् ।
ब्रह्माणीं गि(रि)जां लक्ष्मीं वाणीं वन्दे विभूतये ॥

* * * *

अस्य श्रीमहाविद्यावनदुर्गात्रिपुरसुन्दरीपरमेश्वरीमहामन्त्रस्य अरण्येश्वर ऋषिः, अत्यनुष्टुप् छन्दः, अन्तर्यामिनारायण[ः]किरातरूपधरवनदुर्गा ईश्वरी देवता ; दुं बीजं, ह्रीं शक्तिः, क्रों कीलकं, मम श्रीवनदुर्गामहाविद्याप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

तन्मे भगवति दुर्गे शमय शमय स्वाहा ॥

No. 7173. वनदुर्गामहाविद्यामन्त्रः.

VANADURGĀMAHĀVIDYĀMANTRAḤ.

Pages, 3. Lines, 20 on a page.

Begins on fol. 25*a* of the MS. described under No. 5574.

Complete.

Similar to the above

Beginning:

श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं
सिद्धौघं वटुकत्रयं पदयुगं दूतिक्रमं मण्डलम् ।
वीराद्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकं
श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥

अस्य श्रीवनदुर्गामहाविद्यामहामन्त्रस्य अरण्येश्वर ऋषिः, अत्यनुष्टुप् छन्दः, अन्तर्यामिनारायण[ः]किरातरूपधारिणी ईश्वरी वनदुर्गा

देवता; दुं बीजं, ह्रीं शक्तिः, क्रों कीलकं, मम वनदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

See under the previous number for the end.

No. 7174. वनदुर्गामहाविद्यामन्त्रः.
VANADURGĀMAHĀVIDYĀMANTRAḤ.

Pages, 2. Lines, 9 on a page.

Begins on fol. 37*a* of the MS. described under No. 21, wherein it is given as Vanadurgāmahālaksmīmantra.

Complete.

Similar to the above.

Held to be helpful in the accomplishment of the four Puraṣārthas or principal aims of life, viz, Dharma, Artha, Kāma and Mōksa

Beginning:

अस्य श्रीवनदुर्गामहाविद्यास्तोत्रराजमहामन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, अन्तर्यामिकिरातरूपधरईश्वरी महाविद्या वनदुर्गा देवता; दुं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, मम धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः । मूलमन्त्रेण प्राणायामत्रयं कृत्वा, मूलेन करशुद्धिं कृत्वा

End:

सह नाववतु —ओं शान्तिः शान्तिः ओं । उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥

No. 7175. वनदुर्गामहाविद्यामन्त्रः.
VANADURGĀMAHĀVIDYĀMANTRAḤ.

Pages, 3. Lines, 7 on a page.

Begins on fol. 71*b* of the MS. described under No. 5639, wherein it is found included in the Mahāvidyā 58*a*, given in the list of other works.

Complete.

Similar to the above.

The transcription of this manuscript is said to have been completed by Cennubhaṭla Bhavānīśaṅkara on Wednesday, the 2nd of the bright fortnight of the month of Caitra, in the year Bhava, and the transcript handed over to the brother of Appayya of the Kolcina family.

Beginning :

पूर्णमदः पूर्णमिदं . . . पूर्णमेवावशिष्यते ॥

पुनः षडङ्गन्यासः ।

अस्य श्रीवनदुर्गामहामन्त्रस्य अरण्येश्वर ऋषिः, अत्यनुष्टुप् छन्दः, अन्तर्यामिनारायणकिरातरूपधरेश्वरी श्रीवनदुर्गा महात्रिपुरसुन्दरी देवता ; दुं बीजं, ह्रीं शक्तिः, क्रों कीलकं, मम श्रीवनदुर्गामम(हा)त्रिपुरसुन्दरी-प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः । इति वामहस्तेन जलं दद्यात् । अनेन श्रीवनदुर्गामहा-विद्यापारायणेन भगवती सर्वात्मिका श्रीवनदुर्गा देवता सुप्रीतस्सु(ता सु)-प्रसन्नो(न्ना) वरदो(दा) भवतु ॥

No. 7176. वनदुर्गामहाविद्यामालामन्त्रः.

VANADURGĀMAHĀVIDYĀMĀLĀMANTRAḤ

Pages, 19. Lines, 7 on a page.

Begins on fol. 59*a* of the MS. described under No. 235, wherein it is given as Mahāvidyā in the list of other works.

Complete.

This Mantra is also addressed to Vanadurgā. It contains also other connected Mantras which are considered to be accessories to the Vanadurgāmantra Its repetition is believed to be efficacious in enabling one to destroy one's enemies

Beginning :

हेतुकं पूर्वपीठे तु आग्नेय्यां त्रिपुरान्तकम् ।
दक्षिणे चाग्निवेतालं नैरृत्यां यमजिह्विकम् ॥

* * * *

ओं ह्रीं श्रीं सकलनरमुखभ्रमरीं, ओं क्लीं ह्रीं सकलराजमुखभ्रमरीं, ओं क्रों सौः सकलदेवतामुखभ्रमरीं, ओं क्लीं ह्रीं सकलकामिनीमुखभ्रमरीं, ओं ऐं सौः सकलदेशमुखभ्रमरीं, ओं ह स ख फ्रें त्रैलोक्यचित्तभ्रमरीं, . . . मम वाञ्छितार्थाकर्षिणीं परमकल्याणीं महायोगिनीं महाविद्याम् ।

End:

ओं ब्लूं ह्रीं श्रीब्रह्मकोशाधि(ङि)मां रक्ष रक्ष हुं फट् स्वाहा । उ त्वा मदन्तु स्तोमाः कृणुष्व राधोऽद्रिवः । अव ब्रह्म द्विषो जहि । श्रीवनदुर्गार्पणमस्तु ॥

No. 7177. वनदुर्गामहाविद्यामालामन्त्रः.

VANADURGĀMAHĀVIDYĀMĀLĀMANTRAḤ.

Pages, 13. Lines, 9 on a page.

Begins on fol. 37*b* of the MS. described under No. 21, wherein it has been omitted to be included in the list of other works given therein. Rākṣasadigbandhana stated therein as beginning on 40*a* is found merged in this Mantra

Complete.

Similar to the above.

See under the previous number for the beginning.

End:

अव ब्रह्म द्विषो जहि । सह नाववतु—द्विषावहै । ओं शान्तिश्शान्तिश्शान्तिः . . . .

निर्याणमुद्रादेवतार्पणं यथासुखं विहरेत् ॥

दध्यन्नं क्षीरमिश्रं च सघृतं गुडपूपकम् ।
कदलीपनसाम्रं च मधु मध्वन्नकं तथा ॥

Colophon:

महाविद्या सम्पूर्णा ॥

No. 7178. वनदुर्गामहाविद्यामालामन्त्रः.

VANADURGĀMAHĀVIDYĀMĀLĀMANTRAḤ.

Pages, 29. Lines, 7 on a page.

Begins on fol. 57*b* of the MS. described under No. 5639, wherein it is given as Mahāvidyā 58*a*.

Complete.

Similar to the above

See under No. 7176 for the beginning.

End:

दुं दुर्गायै नमः—दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः । अव ब्रह्म द्विषो जहि । सह नाववतु . . मा विद्विषावहै । ओं शान्तिश्शान्तिश्शान्तिः—इति त्रि ॥

No. 7179. वनदुर्गामहाविद्यामालामन्त्रः.

VANADURGĀMAHĀVIDYĀMĀLĀMANTRAḤ.

Pages, 31. Lines, 4 on a page.

Begins on fol. 176*a* of the MS. described under No. 29, wherein it has been included in Vanadurgāstōtra 174*a*.

Complete.

Similar to the above.

See under No. 7176 for the beginning.

End:

घृणिस्सूर्य आदित्यों श्रीं सहस्रार हुं फट् स्वाहा । अव ब्रह्म द्विषो जहि । उत्तरन्यासः । लं पृथिव्यादिपञ्चपूजां कृत्वा निर्याणमुद्रां प्रदर्शयेत् ॥

Colophon:

श्रीमहाविद्या सम्पूर्णा ॥

No 7180. वनदुर्गामहाविद्यामालामन्त्रः.
VANADURGĀMAHĀVIDYĀMĀLĀMANTRAḤ.

Pages, 42. Lines, 20 on a page.

Begins on fol. 42*a* of the MS. described under No. 5574, wherein it is included in Vanadurgāmahāvidyā 41*a*.

Complete.

Similar to the above.

For the beginning, see under No. 7176.

End:

सद्यो जातं प्रपद्यामि सदाशिवों । नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः ।

मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे
हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिने(नि) ।
निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे
शुम्भध्वंसिनि संहराशु दुरित दुर्गे नमस्तेऽम्बिके ॥

सह नाववतु . . मा विद्विषावहै । ओं शान्तिश्शान्तिश्शान्तिः ॥

No. 7181. वनदुर्गामहाविद्यामालामन्त्रः.
VANADURGĀMAHĀVIDYĀMĀLĀMANTRAḤ.

Pages, 23. Lines, 20 on a page.

Begins on fol. 26*b* of the MS. described under No. 5574, wherein it is included in Vanadurgāmahāvidyā 25*a* given therein in the list of other works

Complete.

Same as the above.

No 7182. वनदुर्गामहाविद्यामालामन्त्रः.
VANADURGĀMAHĀVIDYĀMĀLĀMANTRAḤ.

Pages, 32. Lines, 8 on a page.

Begins on fol. 103*a* of the MS. described under No. 124, wherein it is found in Mahāvidyāvanadurgā 102*a* given therein in the list of other works.

Complete.
Similar to the above.

Beginning:

ओं ह्रीं हुं ओं नमो भगवति चिन्तामणि दुर्गे उत्तिष्ठ पुरुषि महाविद्यावनदुर्गारूपिणि शूलिनि दुर्गे किं स्वपिषि चण्डिके मधुकैटभ-संहारिणि ।

End:

वर्षन्त—द्विषो जहि ओं उत्तिष्ठ पुरुषि हृ, किं स्वपिषि शिरसे, भयं मे समुपस्थितं शिखायाः . . . .

वनदुर्गाध्यानम्—

सौवर्णाम्बुजमध्यगां त्रिणयनां सौदामिनीसन्निभां
शङ्खं चक्रगदाभयानि दधतीमिन्दोः कलां बिभ्रतीम् ।
ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैस्स्तुतां
ध्यायेऽहं ध्वनि(चिति)वासिनीं शशिमुखीं पार्श्वस्थवश्येऽन(न्व)हम् ॥

No. **7183.** वनदुर्गामहाविद्यामालामन्त्रः.

VANADURGĀMAHĀVIDYĀMĀLĀMANTRAḤ.

Pages, 58. Lines, 7 on a page.

Begins on fol. 13*a* of the MS. described under No. 7156.
Complete.
Same as the above.

No. **7184.** वनदुर्गामहाविद्यामालामन्त्रः.

VANADURGĀMAHĀVIDYĀMĀLĀMANTRAḤ.

Pages, 7. Lines, 19 on a page.

Begins on fol. 45*b* of the MS. described under No. 2886
Complete.
Similar to the above.

Beginning:

मालामन्त्रः—

ह्रीं दुं ओं नमो भगवति चिन्तामणि महादुर्गे उत्तिष्ठ पुरुषि महाविद्यावनदुर्गारूपिणि शूलिनि दुर्गे किं स्वपिषि चण्डिके मधुकैटभसंहारिणि ।

End:

प्रतिकूलं मे नश्यतु, अनुकूलं मे ऽस्तु । महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् । ओं ब्लूं ह्रीं श्रीं ब्रह्मकोशेन मां रक्ष रक्ष हुं फट् स्वाहा ।

अव ब्रह्म द्विषो जहि . . . . . हेमप्रख्यामित्यादिध्यानं, मूलमन्त्रजपं कृत्वा मालामन्त्रं दशवारं जपेत् ॥

No. **7185.** वनदुर्गामालामन्त्रः.

VANADURGĀMĀLĀMANTRAḤ.

Pages, 2. Lines, 20 on a page.

Begins on fol. 41*b* of the MS. described under No. 5574.

Complete.

This Mantra is in praise of Vanadurgā; and its repetition is considered to have the power to counteract the evils caused by minor spirits. It differs from Vanadurgāmahāvidyāmālāmantra in that it does not contain the accessory Mantras.

Beginning:

ओं ह्रीं दुर्गामालामन्त्रः—

ओं नमो भगवति चिन्तामणि महादुर्गि उत्तिष्ठ पुरुषि महाविद्यावनदुर्गारूपिणि शूलिनि दुर्गि किं स्वपिषि चण्डिके मधुकैटभसंहारिणि ।

End:

क्षुद्रोपद्रवं छिन्धि छिन्धि भिन्धि भिन्धि खें खें खें खें हुं हुं हुं फट् फट् फट् स्वाहा ॥

No. 7186. वनदुर्गामालामन्त्रः.
VANADURGĀMĀLĀMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 2'a of the MS. described under No. 2424, wherein it is found in the Vanadurgāmantra 28a which is given in the list of other works.

Complete.

Similar to the above.

Beginning:

मालामन्त्रः—

ओं नमः कृष्णवाससि सहस्रकोटिसिंहासने सहस्रपादसहस्रभुजसहस्रवदने सहस्रत्रिणेत्रोज्ज्वले ।

End:

कालरात्रि प्रत्यङ्गिरे दुर्गे मां रक्ष रक्ष सर्वशत्रून् भक्ष भक्ष हुं फट् स्वाहा । यन्त्रम्—

त्रिरेखा च त्रिशूलं च मध्ये शूलचतुष्टयम् ।
प्रणवेन वेष्टते युक्तं मूलमन्त्रं समालिखेत् ॥
दुरितं(?) दुष्टसंहारं दुर्गामन्त्रं समालिखेत् ।

No. 7187. वराहचतुर्दशाक्षरमन्त्रः.
VARĀHACATURDAŚĀKṢARAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Beigns on fol 9a of the MS. described under No. 5786.

Complete.

The repetition of this Mantra, consisting of 14 syllables, is intended to secure the favour of Viṣṇu in his incarnation as Varāha.

Beginning:

पूर्णज्ञानेत्यादिषडङ्गन्यासः ।

ओं नमो भगवते महावराहाय स्वाहा इति प्राणायामः १२.

* * * *

अस्य श्रीचतुर्दशाक्षरवराहमन्त्रस्य ब्रह्मा ऋषिः, शक्करी छन्दः, श्रीवराहो देवता ; श्रीवराहप्रेरणया वराहप्रीत्यर्थे जपे विनियोगः।

End:

चतुर्दशाक्षरवराहमन्त्रजपङ्करिष्ये ।

ओं नमो भगवते महावराहाय स्वाहा—इति जपः। उपसंहारः पूर्ववत् ॥

No. **7188.** वराहत्रयस्त्रिंशदक्षरमन्त्रः.

VARĀHATRAYASTRIṀŚADAKṢARAMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 8*a* of the MS. described under No. 5786.

Complete.

Similar to the above.

This Mantra consists of 33 syllables. Its repetition is believed to be efficacious in bestowing sovereignty on one.

Beginning:

ओं हुं नमो भगवते वराहरूपाय भूर्भुवस्स्वःपतये भूपतित्वं मे देहि दापय स्वाहा। इति प्राणायामः १२.

* * * *

अस्य श्रीत्रयस्त्रिंशदक्षरवराहमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीवराहो देवता ; श्रीवराहप्रेरणया श्रीवराहप्रीत्यर्थे जपे विनियोगः ।

End:

ओं हुं नमो भगवते वराहरूपाय भूर्भुवस्स्वः पतये भूपतित्वं मे देहि दापय स्वाहा--इति जपः। उपसंहारः पूर्ववत् ॥

No. **7189.** वराहमालामन्त्रः.

VARĀHAMĀLĀMANTRAḤ.

Pages, 3. Lines, 4 on a page.

Begins on fol. 170*a* of the MS. described under No. 2848, wherein this Mantra has been omitted to be included in the list of other works given therein.

Complete.

The repetition of this Mantra is believed to have the power to enable one to acquire wealth.

Beginning:

(अथ श्रीवरा)हमन्त्रविधानमुच्यते—भार्गव ऋषिः, अनुष्टुप् छन्दः, श्रीवराहो देवता ; हुं बीजं, स्वाहा शक्तिः, श्रीं कीलकं, वराहप्रसाद-सिद्ध्यर्थे जपे विनियोगः ।

End:

ओं नमो भगवते वराहरूपाय . . . . द्रव्यं मे देहि
दापय स्वाहा— इति मन्त्रः। लक्षं जपः।
त्रिमधुरासि(ते)क्षुपद्मैर्दशांशहोमः ॥

No. **7190.** वराहसप्ताक्षरमन्त्रः.

VARĀHASAPTĀKṢARAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 8*b* of the MS. described under No. 5786.

Complete.

This Mantra consists of seven syllables. It is also addressed to Viṣṇu in his incarnation as Varāha.

Beginning:

ओं हुं वराहाय नमः ओं (इति प्रणायामः) १२.

* * * *

अस्य सप्ताक्षरवराहमन्त्रस्य ब्रह्मा ऋषिः, उष्णिक छन्दः, श्री-वराहो देवता; श्रीवराहप्रेरणया श्रीवराहमन्त्रजपे विनियोगः ।

End:

सप्ताक्षरवराहमन्त्रजपङ्क्तिर्ध्ये—

ओं हुं वराहाय नमः ओं—इति जपः । उपसंहारः पूर्ववत् ॥
वराहमन्त्रस्य षडङ्गन्यासः॥

No. 7191. वर्णमालिका.

VARṆAMĀLIKĀ

Pages, 3. Lines, 6 on a page.

Begins on fol. 21*a* of the MS. described under No. 217.

Complete.

Herein the series of letters making up the alphabet is looked upon as a Mantra. These letters are taken singly or collectively and repeated along with other Mantras.

Beginning:

अस्य श्रीवर्णमालिकामहामन्त्रस्य शब्दब्रह्म ऋषिः, नाना छन्दांसि, अकारादि त्रिरेखान्तरी सुषुम्ना कुण्डलिनी सरस्वती देवता ; चतुस्त्रिंशद्वर्णा बीजं, पञ्च स्वराश्शक्तयः, स्वरवर्णमयं कीलकं, मम श्रीवर्णमालिकाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

क्षः हः सः षः शः वः लः रः यः मः भः बः फः पः नः धः दः थः तः णः ढः डः ठ टः ञः झः जः छ. चः ङः घः गः खः कः अः अं औः ओः ऐः एः ऊः उः ईः इः आ : अः इति एकैकवर्णानुच्चार्य मन्त्रं जप्त्वा वर्गक्रमेण जप्त्वा एवमष्टोत्तरशतं जप्त्वा तत उद्वसेत् ॥

No. 7192. वशीकरणवाराहीमन्त्रः.

VAŚĪKARAṆAVĀRĀHĪMANTRAḤ

Pages, 4. Lines, 6 on a page.

Begins on fol. 35*a* of the MS. described under No. 3862.

Complete.

The repetition of this Mantra, which is addressed to Vārāhī i.e., Viṣṇu's Śakti conceived as a goddess, is believed to have the power to enable one to bring people under one's control and influence.

Beginning:

अस्य श्रीवशीकरणवाराहीमहामन्त्रस्य अज ऋषिः, गायत्री छन्दः, वशीकरणवाराही देवता ; क्रों बीजं, ऐं शक्तिः, क्लीं कीलकं, मम वशीकरणवाराहीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ओं ब्लूं ऐं ग्लौं नमो भगवति वाराहि सर्वजनं मे वशमानय वौषट् ठ ठ ठ ठ हुं फट् स्वाहा ॥

End:

वशीकरणबाणस्त्वं भक्तानामनिवारितः ।
तस्मादवश्यं वाराहि जगत्सर्वं वशं कुरु ॥
वश्यस्तोत्रमिदं देव्यास्त्रिसन्ध्यं यः पठेन्नरः ।
सोऽपि वश्यं नयेत्सर्वं कामं राजानमेव च ॥

No. **7193.** वश्यवाराहीमन्त्रः.

VAŚYAVĀRĀHĪMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 198*b* of the MS. described under No. 119, wherein it is given as Vārāhīstōtra.

Complete.

Similar to the above.

Beginning:

मुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वलोकवशङ्करि अमुकं वशमानय स्वाहा ।

End:

तद्वाह्येऽष्टदलं प्रो . . . पत्रे मनःप्रिये ।
चतुरश्रन्तु तद्वाह्ये देवि देव्यासनं भवेत् ॥

No. **7194.** वश्यवाराहीमन्त्रः.

VAŚYAVĀRĀHĪMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 2*a* of the MS. described under No. 5586 wherein it is given as Vaśyavārāhīstōtra.

Complete.

Similar to the above.

Beginning:

अस्य श्रीवशीकरणी(ण) वाराहीस्तोत्रमन्त्रस्य अज ऋषिः, गायत्री छन्दः, वशीकरणी वाराही देवता; ग्रां बीजं, ग्रीं शक्तिः, ग्रूं कीलकं, मम श्रीवशीकरणवाराहीप्रसादसिद्ध्यर्थे जपे विनियोग ।

End:

मूलम्—

वाराहि सर्वजनं मे वशमान[ा]य वौषट् ठं ठं ठं ठं ओं फट् स्वाहा ॥

No. **7195.** वागीश्वरीमन्त्रः.

VĀGĪŚVARĪMANTRAḤ.

Pages, 2. Lines, 27 on a page.

Begins on fol 229*a* of the MS. described under No. 581, wherein it is included in the Mantramālikā 229*a*.

Complete.

The Mantra is addressed to Vāgīśvarī, who is the same as Sarasvatī; and its repetition is considered to have the power to enable one to become a learned poet.

Beginning:

अस्य श्रीवागीश्वरीमन्त्रस्य कण्व ऋषिः, विराट् छन्दः, श्रीवागीश्वरी देवता; वं बीजं, स्वाहा शक्तिः, मम वाक्सिद्ध्यर्थे जपे विनियोगः ।

End:

मन्त्रः—

ओं ऐं वद वद वाग्वादिनि स्वाहा ॥ एवं ध्यात्वा षोडशोपचारं कुर्यात् ।

* * * *

वत्सरात्कवित्वं वाक्सिद्धिश्च भवति ॥

No. **7196.** वागीश्वरीमन्त्रः.
VĀGĪŚVARĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 86*a* of the MS. described under No. 5566.

Complete.

Same as the above.

No. **7197.** वागीश्वरीमन्त्रः.
VĀGĪŚVARĪMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 273*a* of the MS described under No. 5477, wherein it is included in the Mantramālikā 273*a* given therein in the list of other works.

Complete.

Same as the above ; but no mention is made of the Ṛṣi (sage), Chandas (metre), and Dēvatā (the presiding deity).

No. **7198.** वागिश्वरीमन्त्रः.
VĀGĪŚVARĪMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 22*a* of the MS. described under No. 5673, wherein it is included in the Āmnāyamantramālikā 1*a* given therein in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीवागीश्वरीमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः, गायत्री छन्दः, श्रीवागीश्वरी देवता ; ऐं बीजं, ह्रीं शक्तिः, सौः कीलकं, मम श्रीवागिश्वरीप्रसादसिद्ध्यर्थे विनियोगः ।

End:

मनुः—
ऐं ह्रीं सौः वद वद वाग्वादिनि स्वाहा ।
वागीश्वरीश्री ।

आरोधनकरी माया त्रिगुणा जगदात्मिके (का) ।
तमस्स्वरूपिणी ध्येयानो(चो)त्तराम्नायदेवता ॥

* * * *

इत्युत्तरात्रायदेवताश्चानाहते मनश्चके च पूजयेत् ॥

No. 7199. वाग्वादिनीमन्त्रः.

VĀGVĀDINĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 232*b* of the MS. described under No. 124, wherein it is found in the Ṣaḍāmnāyamantra 228*b*.

Complete.

Similar to the above.

Beginning :

अस्य श्रीवाग्वादिनीमन्त्रस्य दक्षिणामूर्तिः ऋषिः, गायत्री छन्दः, वाग्वादिनी देवता; ऐं बीजं, ह्रीं शक्तिः, सौः कीलकं, वाग्वादिनी-प्र—गः ।

End ;

ऐं ह्रीं सौः वद वद वाग्वादिनि स्वाहा । वाग्वादिनीदिव्यश्री-मः, ऐं ह्रीं श्रीं स्फ्रें महाचण्डयोगीश्वरी—उत्तराम्नायसमयविद्येश्वरी—कालसङ्कर्षण्यम्बादिव्य—मः ॥

No. 7200. वाग्वादिनीमन्त्रः.

VĀGVĀDINĪMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 8*b* of the MS. described under No. 673, wherein it is found in the Ṣaḍāmnāya 1*a*.

Complete.

Similar to the above.

Beginning:

अस्य श्रीवाग्वादिनीमन्त्रस्य दक्षिणामूर्तिः ऋषिः, गायत्री छन्दः, वाग्वादिनी देवता; ऐं बीजं, ह्रीं शक्तिः, सौः कीलकं, मम वाग्वादिनीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ऐं ह्रीं श्रीं सौः वद वद वाग्वादिनि स्वाहा । वाग्वादिन्यम्बाश्रीपा—नमः । . . . . . .

द्विसहस्रदेवतापरिवारिताय ओड्याणपीठाय नमः । ओड्याणपीठश्री—नमः ॥

Colophon:

इत्युत्तराम्नायः ॥

No. **7201.** वाग्वादिनीमन्त्रः.

VĀGVĀDINĪMANTRAḤ.

Page, 1. Lines, 11 on a page.

Begins on fol. 1*a* of the MS. described under No. 5683.

Complete.

Similar to the above.

Beginning:

अथ वागीश्वरीमन्त्रविधानमुच्यते—

(अस्य श्रीवाग्वादिनीमन्त्रस्य) कण्व ऋषिः, विराट् छन्दः, वागीश्वरी देवता; ऐं बीजं, स्वाहा शक्तिः, मातृकावदङ्गानि ।

End:

विद्याप्रधानोऽयं मन्त्रः, अक्षरलक्षं जपेत् पुरश्चरणार्थम्; सितैः कमलैः पयस्सिक्तैः . . . . पुरश्चरणहोमः ॥

No. **7202.** वाग्वादिनीमालामन्त्रः.

VĀGVĀDINĪMĀLĀMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 62*a* of the MS. described under No. 5885.

Complete.

This Mantra is in praise of the goddess Vāgvādinī under various significant names.

Beginning :

हं साध्यबन्धनाय, ह्रीं सर्वभूतिप्रदाय, ऐं वाक्प्रदाय, क्लीं सर्वजगद्वशीकरणाय, सौः सर्वसंक्षोभणाय, श्रीं महासंपत्प्रदाय, ग्लौं भूमण्डलाधिपत्यप्रदाय, द्रां चोरजीविने, ब्लूं संमोहनाय, ओं मोक्षप्रदाय ।

End :

ऐं क्लीं सौः वद वद वाग्वादिनि स्वाहा । सौः क्लीं ऐं ओं खें खें मारय मारय ह्रीं ह्रीं मम सकलाभिवृद्धये मनस्संपन्नय स्वाहा ॥

No. **7203.** वामनमन्त्रः.

VĀMANAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 11*b* of the MS. described under No. 5786.

Complete.

The repetition of this Mantra is believed to have the power to secure the favour of Vāmana, an incarnation of Viṣṇu

Beginning :

ओं वां वामनाय नमः इति प्राणायामः १२. . . . .

अस्य श्रीवामनमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, वामनो देवता ; वामनप्रेरणया वामनप्रीत्यर्थे जपे विनियोगः ।

End :

वामनमहामन्त्रजपङ्करिष्ये ।

ओं वां वामनाय नमः ओं इति जपः । उपसंहारः पूर्ववत् ॥

No. 7204. वामनमन्त्रः.
VAMANAMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 325*a* of the MS. described under No. 5477, wherein it is included in the Mantramālikā (Ākāśabhairavakalpa) 273*a* given therein in the list of other works.

Complete.

Similar to the above.

Vāmana is herein looked upon as the giver of food.

Beginning:

अस्य श्रीवामनमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, (श्रीवामनो देवता,) श्रीवामनप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओन्नमो भगवते विष्णवे अन्नाधिपतये स्वाहा—इति मन्त्रः दशसहस्रं जपः । इति ।

No. 7205. वायव्यास्त्रमन्त्रः.
VĀYAVYĀSTRAMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 27*a* of the MS. described under No. 2886.

Complete.

It is stated herein that the repetition of this Mantra is a necessary preliminary to the use of the Brahmāstra.

Beginning:

आ वायव्यया वायव्या और्वाय या वा—इति वायव्यास्त्रेण नववारं प्राणानायम्य ब्रह्मास्त्रप्रयोगार्थं वायव्यास्त्रमन्त्रजपं करिष्ये—

अस्य श्रीवायव्यास्त्रप्रयोगमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः। महाभूतवायुर्देवता; यां बीजं, स्वाहा शक्तिः, जगत्सृष्टिरिति कीलकं,, ब्रह्मास्त्रप्रयोगार्थं वायव्यास्त्रप्रयोगे विनियोगः ।

End:

पञ्चोपचारैरभ्यर्च्य वायव्यास्त्रं त्रिवारं जपेत् ॥

No. 7206. वाराहीकवचः.
VĀRĀHĪKAVACAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 16*b* of the MS described under No. 5661, wherein it has been omitted to be included in the list of the other works contained therin.

Complete.

The repetition of this Kavacamantra, which is addressed to the goddess Vārāhī, is believed to have the power to secure protection to one from all dangers and to enable one to destroy one's enemies.

Beginning:

अस्य श्रीवाराहीकवचस्य त्रिलोचन ऋषिः, अनुष्टुप् छन्दः, श्री-वाराही देवता; ओं बीजं, ग्लौं शक्तिः, स्वाहा इति कीलकं, मम सर्वशत्रुनाशनार्थे जपे विनियोगः । . . . .

वार्ताली मे शिरः पातु वाराही फालमुत्तमम् ।
नेत्रे वराहवदना पातु कर्णौ तथान्धिनी ॥

End:

वाराहीकवचं नित्यं त्रिसन्ध्यं यः पठेन्नरः ॥
तथाविधं भूतगणा न स्पृशन्ति कदा चन ।
आपदश्शत्रुचोरादिग्रहदोषाश्च(शु) सम्भवाः ॥
माता पुत्रं यथा वत्सं धेनुः पक्ष्मेव लोचनम् ।
तथाङ्गमेव वाराही रक्ष रक्षेति सर्वदा ॥

Colophon:

इति वाराहीकवचं संपूर्णम् ॥

No. 7207. वाराहीमन्त्र.
VĀRĀHĪMANTRAḤ.

Pages, 3. Lines, 18 on a page.

Begins on fol. 16*b* of the MS. described under No. 5673, wherein it is included in the Āmnāyamantramālikā 1*a*.

Complete.

The proper repetition of this Mantra, which is addressed to the goddess Vārāhī, is believed to be efficacious in bringing people under one's influence and control.

Beginning:

अस्य श्रीवाराहीमहामन्त्रस्य धरणीवराह ऋषिः, गायत्री छन्दः, श्रीवाराही देवता; ग्लौं बीजं, ऐं शक्तिः, सौः कीलकं, मम श्रीवाराही-प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—

ऐं ग्लौं ओं नमो भगवति वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि . . . . शीघ्रं वश्यं कुरु कुरु ऐं ग्लौं ठ ठ ठ ठ हुं फट् स्वाहा । श्रीवाराह्यम्बाश्रीपादुकाम् ॥

No. 7208. वाराहीमन्त्रः.

VĀRĀHĪMANTRAḤ.

Page, 1. Lines, 4 on a page.

Begins on fol. 244*a* of the MS. described under No. 537.

Complete.

Similar to the above.

Beginning:

अस्य श्रीवाराहीमहामन्त्रस्य धरावराह ऋषिः, गायत्री छन्दः, वाराही देवता; ग्लौं बीजं, ऐं शक्तिः, सौः कीलकं, मम वाराहीसिद्ध्यर्थे विनियोगः ।

End:

शीघ्रं वश्यं कुरु कुरु ऐं ग्लौं ठ ठ ठ ठ हुं फट् स्वाहा ।

दिग्बन्धः । मूलम्—

दंष्ट्रोल्लसत्पोत्रिमुखारविन्दकोटीरसंभिन्नहिमांशुरेखाम् ।
हलं कपालं मुसलं दधानामात्रासिनीं दुर्घटकाननस्थाम् ॥

ऐं ग्लौं सौः ॥

No. 7209. वाराहीमन्त्रः.
VĀRĀHĪMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 135*a* of the MS. described under No. 537.

Complete.

This Mantra is addressed to the holy sandals of the goddess Vārāhī.

Beginning:

अस्य श्रीवाराहीमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, वाराहीगुरुपादुका देवता ; ऐं ग्लामिति बीजं, ह स शक्तिः, स ह कीलकम् ।

End:

श्रीगुर्वङ्घ्रिलसद्भूषां कपालासिधरां शिवाम् ।
नीलमेघप्रभां वन्दे वाराहीगुरुपादुकाम् ॥
ऐं ग्लौं ह्रस्फ्रं । शेषं पूर्ववत् ॥

No. 7210. वारुणमन्त्रः.
VĀRUṆAMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 59*a* of the MS. described under No. 5987.

Complete.

The repetition of this Mantra addressed to Varuṇa is believed to bring about a downpour of rain

Beginning:

अस्य श्रीवारुणमहामन्त्रस्य विभाण्डकपुत्र ऋश्यशृङ्ग ऋषिः, देवी गायत्री छन्दः, पर्जन्यो देवता; वं बीजं, वारुणी शक्तिः, अस्मिन् देशे सद्यस्सुवृष्टिं कुरु कुरु स्वाहेति कीलकं, अस्मिन् देशे अवग्रहदोषनिवृत्त्यर्थे अतिवृष्टिसिद्ध्यर्थे जपे विनियोगः ।

End:

समुद्रमध्यनिलयं वारुणीपतिमव्ययम् ।
प्रभुं सुवृष्टिदातारं वन्देऽहं वरुणं सदा ॥

मनुः—
ओं(वं) अस्मिन् देशे सद्यस्सुवृष्टिं कुरु कुरु स्वाहा ॥

No. 7211. वासुदेवद्वादशाक्षरमन्त्रः.
VĀSUDĒVADVĀDAŚĀKṢARAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 6*a* of the MS. described under No. 5786.

This Mantra consists of 12 syllables. Its repetition is believed to please Viṣṇu as Vāsudēva

Beginning:

अथ वासुदेवद्वादशाक्षरमन्त्रः—ओं नमो भगवते वासुदेवायेति प्राणायामः १२.

ओं केशवाय नमः शिरसि, ओं नारायणाय नमः नेत्रयोः,

* * * *

अस्य श्रीवासुदेवद्वादशाक्षरमन्त्रस्य अन्तर्यामी ऋषिः, जगती छन्दः, श्रीवासुदेवो देवता ; श्रीवासुदेवप्रेरणया श्रीवासुदेवप्रीत्यर्थे श्रीवासुदेवद्वादशाक्षरमन्त्रजपे विनियोगः ।

End:

वासुदेवद्वादशाक्षरमन्त्रजपं करिष्ये—

ओं नमो भगवते वासुदेवाय ओं—इति जपः । उपसंहारः पूर्ववत् ॥

No. 7212. विकलयक्षिणीमन्त्रः.
VIKALAYAKṢIṆĪMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 251*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a*.

Complete.

This Mantra is addressed to an aged Yakṣiṇī ; and its repetition is believed to be conducive to one's prosperity and well-being.

Beginning and **End**:

मन्त्रः—विकले ऐं ह्रीं श्रीं क्लीं स्वाहा।

ग्रहेण मासत्रयं जपं कुर्यात्। पूर्वोक्तदशांशहोमः। अष्टैश्वर्यप्रदो भवति॥

No. **7213.** विकलयक्षिणीमन्त्रः.

VIKALAYAKṢIṆĪMANTRAḤ

Page, 1. **Lines**, 18 on a page.

Begins on fol. 297*a* of the MS. described under No. 5477 wherein it is found in the Mantramālikā 273*a*.

Complete.

Same as the above.

No. **7214.** विकलयक्षिणीमन्त्रः.

VIKALAYAKṢIṆĪMANTRAḤ.

Page, 1. **Lines**, 10 on a page.

Begins on fol. 99*a* of the MS. described under No. 5566, wherein it has been omitted to be included in the list of other works.

Complete.

Same as the above.

No. **7215.** विघ्नेश्वरकवचः.

VIGHNEŚVARAKAVACAḤ.

Pages, 6. **Lines**, 19 on a page.

Begins on fol. 68*a* of the MS. described under No. 426, wherein it is given as Gaṇēśakavaca.

Complete as found in the Bhaviṣyōttara Purāṇa.

This Kavaca-mantra is addressed to the god Vināyaka; and its repetition is believed to have the power to secure protection to one from dangers and to remove one's diseases.

Beginning:

नन्दिकेश्वर सर्वज्ञ भक्तानुग्रहकारक।
भक्तिमुक्तिप्रदं नृणां सर्वरक्षाकरं परम्॥

* * * *

कवचं श्रोतुमिच्छामि सर्वकामार्थसाधनम् ।

* * * *

श्रीनन्दिकेश्वर उवाच—

शृणु ब्रह्मन् प्रवक्ष्यामि गुह्याद्गुह्यतमं महत् ।
विघ्नेशकवचं पुण्यं पवित्रं पापनाशनम् ॥

* * * *

अस्य श्रीमहागणेशकवचमहामन्त्रस्य आदिपुरुषोत्तमऋषये नमः, अनुष्टुप्छन्दसे नमः, श्रीगणेश्वरदेवतायै नमः, गं बीजाय नमः, ह्रीं शक्तये नमः, श्रीं कीलकाय नमः, श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

* * * *

विघ्नेशः पार्श्वतः पातु गणाध्यक्षस्तु दक्षिणे ।
पश्चिमे गजवक्रस्तु उत्तरे त्वघनाशनः ॥

End:

जलस्थलगतो वापि पातु मायापहारकः ।
सर्वत्र पातु सर्वेशः सर्वलोकेषु संश्रयः ॥

अभेद्यकवचं गुह्यं पवित्रं पापनाशनम् ।
प्रातः काले जपेन्नित्यं सदा व्याधिनिवारणम् ॥

* * * *

यं ब्रह्मचारिणमचिन्त्यमनेकरूपं ध्यायेज्जगद्धितमशेषदमापदघ्नम् ।
यस्सर्वसिद्धिभ(म)जतां ददतां वरिष्ठं विघ्नेश्वर सकलसिद्धिकरश्च नृणाम् ॥

Colophon:

इति भविष्योत्तरपुराणे चतुर्थखण्डे . . . . . विघ्नेश्वरकवचं सम्पूर्णम् ॥

No. **7216.** विघ्नेश्वरकवचः.

VIGHNEŚVARAKAVACAḤ

Pages, 11. Lines, 5 on a page.

Begins on fol. 18*a* of the MS. described under No. 1872, wherein it is given as Gaṇapatikavaca.

Complete.
Similar to the above.

Beginning:

ब्रह्मोवाच—

नन्दिकेश्वर सर्वज्ञ भक्तानुग्रहकारक ।
भुक्तिमुक्तिप्रदं नृणां सर्वरक्षाकरं परम् ॥

* * * *

अस्य श्रीविघ्नेशकवचमहामन्त्रस्य आदिपुरुषोत्तम ऋषिः, त्रिष्टु-बनुष्टुप् छन्दांसि, श्रीविनायको देवता, गं बीजं, गिं शक्तिः, इदं कीलकं, रक्तवर्णश्रीमहागणपतिप्रीत्यर्थे जपे विनियोगः ।

* * * *

विघ्नेशः पूर्वतः पातु गणाध्यक्षस्तु दक्षिणे ।
पश्चिमे गजवक्रस्तु उत्तरे विघ्ननाशनः ॥

End:

स्वस्तये सकलकार्यसिद्ध्ये वस्तु हस्तिमुखमस्तु मे सदा ॥

* * * *

Colophon:

इति गणपतिकवचं सम्पूर्णम् ॥

No. **7217.** विघ्नेश्वरकवचः.
VIGHNĒŚVARAKAVACAḤ.

Pages, 22. Lines, 4 on a page.
Begins on fol. 1*a* of the MS. described under No. 5953.
Complete, as found in the Brahmāṇḍapurāṇa.
Similar to the above. Held to be efficacious in removing all kinds of sins.

Beginning:

गजाननं भूतगणाधिसेवितं कपित्थजम्बूफलसारभक्षकम् ।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् ॥

ओं ब्रह्मोवाच—

नन्दिकेश्वर सर्वज्ञ भक्तानुग्रहकारकम् ।
कवचं श्रोतुमिच्छामि सर्वकाम्यार्थसाधनम् ॥

*　*　*　*

अस्य श्रीविघ्नेश्वरकवचस्तोत्रमहामन्त्रस्य आदिपुरुषोत्तम ऋषिः, अनुष्टुप् छन्दः, श्रीविघ्नेश्वरो देवता, विं बीजं, घ्नं शक्तिः, शं कीलकं, मम समस्तपापक्षयार्थे जपे विनियोगः ।

End:

सर्वां च सिद्धिं लभते मनुष्यो विघ्नेशसायुज्यमुपैति संशयः ॥
विघ्नेशसायुज्यमुपैति संशयो नमः ॥

Colophon:

इति ब्रह्माण्डपुराणे ब्रह्मनन्दिकेश्वरसंवादे विघ्नेश्वरकवचं सम्पूर्णम् ॥

No. 7218. विघ्नेश्वरमालामन्त्रः.

VIGHNĒSVARAMĀLĀMANTRAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 84*a* of the MS. described under No. 21.

Complete

This Mantra is in praise of Vināyaka under different significant names; and its repetition is held to be efficacious in enabling one to accomplish one's desires.

Beginning and **End:**

ओं यं ब्रह्मेशसुमुखाय लम्बोदराय अभीष्टमहात्मने सर्वकार्यसिद्धिकराय ओं क्रौं भ्यां घां आं ह्रीं क्रों अभीष्टाय स्वाहा। ओं एकदन्ताय लम्बोदराय अभीष्टमहात्मने सर्वकार्यसिद्धिकराय ह्रीं ह्रीं गजाननाय गणपतये स्वाहा ॥

No. 7219. विदारणनृसिंहमन्त्रः.

VIDĀRAṆANṚSIṀHAMANTRAḤ

Page, 1. Lines, 19 on a page.

Begins on fol. 24*a* of the MS. described under No. 2886.

Complete.

This Mantra is addressed to Nṛsiṁha conceived as tearing the demon Hiraṇyakaśipu; and its repetition is believed to have the power to enable one to accomplish one's desires.

Beginning:

अस्य श्रीविदारणनृसिंहस्य नारदो भगवानृषिः, अनुष्टुप् छन्दः, श्रीविदारणनृसिंहो देवता; आं बीजं, लं शक्तिः, गं कीलकं, मम सर्वाभीष्टार्थे विनियोगः ।

End:

श्रीं ह्रीं ओं ओं श्रीं ह्रीं उग्रं वीरमीयते शुचिः । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहं श्रीं ह्रीं ओं श्रीनृसिंहाय विद्महे वज्रनखाय धीमहि । तन्नः(नृ)सिंहः प्रचादेयात् ॥

No. **7220.** विद्यागोपालमन्त्रः.

VIDYĀGŌPĀLAMANTRAḤ

Pages, 2. Lines, 5 on a page.

Begins on fol. 57*a* of the MS. described under No. 5885

Complete.

This Mantra consists in the repetition of a combination of the Kṛṣṇa-mantra with the Śrīvidyā-mantra. Both these Mantras are divided into 3 parts, and the first part of the Śrīvidyā mantra is repeated after the first part of the Kṛṣṇa-mantra, the second after the second, and so on the combination is made as shown below:—

क्लीं कृष्णाय क ए ई ल ह्रीं, गोविन्दाय ह स क ह ल ह्रीं, गोपीजनवल्लभाय स्वाहा स क ल ह्रीं ।

Beginning:

अस्य श्रीविद्यागोपालमन्त्रस्य आनन्दभैरव नारदा ऋषयः, अनुष्टुप् छन्दः, गायत्री छन्दः, श्रीविद्यागोपालो देवता; क्लीं बीजं, स्वाहा शक्तिः, कृष्णाय कीलकं, श्रीविद्यागोपालप्रीत्यर्थे जपे विनियोगः ।

End:

आद्यपादमध्यमं मध्यमे द्वे चान्ते चान्तं योजयित्वा क्रमेण विद्या-मन्त्रं कृष्णमन्त्रेण मन्त्रयेत् ॥

No. 7221. विद्यासम्पुटितमातृकान्यासः.

VIDYĀSAMPUṬITAMĀTṚKĀNYĀSAḤ.

Pages, 2. Lines, 9 on a page.

Begins on fol. 193*b* of the MS described under No. 124, wherein it is found in Daśavidhamātṛkānyāsa 192*a* in the list of other works.

Complete.

On the ceremonial touching of certain parts of the body, while repeating at the same time the series of the Mantra-formulas containing the successive letters of the alphabet introduced into the Śrīvidyā-mantra-formula in the natural as well as the reverse order.

Beginning:

अथ विद्यान्यासः —

अस्य श्रीविद्यासम्पुटितमातृकान्यासस्य दक्षिणामूर्तिः ऋषिः, पङ्क्ति-श्छन्दः, श्रीमहात्रिपुरसुन्दरी देवता; ऐं क ४ व्यञ्जनानि बीजानि, सौः स ३ स्वराश्शक्तयः, क्लीं ह ५ व्यक्तयः कीलकं, ममेष्टदेवता-प्रीतये विद्यासम्पुटितमातृकान्यासे विनियोगः ।

End:

ऐं ह्रीं श्रीं क १४ अं नमः स ३ ह ५ क ४ श्रीं ह्रीं ऐं इत्यादिक्षान्तं न्यसेत् ॥

Colophon:

इति विद्यासम्पुटितमातृकान्यासः ॥

No. 7222. विद्यासंपुटितमातृकासरस्वतीमन्त्रः.

VIDYĀSAṀPUṬITAMĀTṚKĀSARASVATĪMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 140*b* of the MS. described under No. 537.

Complete.

Similar to the above. This Nyāsa is intended to serve as preliminary in relation to the repetition of the Śrīvidyā-mantra.

Beginning:

अस्य श्रीविद्यासंपुटितमातृकासरस्वतीमन्त्रस्य दक्षिणामूर्तिः ऋषिः, पङ्क्तिश्छन्दः, श्रीविद्यासंपुटितमातृका सरस्वती देवता, ऐं क ए बीजं, क्लीं ह स शक्तिः, सौः स क कलिकं, ममोपास्यमानश्रीविद्याङ्गत्वेन श्रीविद्यासंपुटितमातृकासरस्वती(न्यासे) विनियोगः ।

End:

ऐं ह्रीं श्रीं क ए ह स स क अं क ए ह स स क नमः इति क्षन्नमः-पर्यन्तम् ॥

No. 7223. विद्युज्जिह्वामन्त्रः.

VIDYUJJIHVĀMANTRAḤ.

Page, 1 Lines, 27 on a page.

Begins on fol. 252*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* in the list of other works.

Complete.

The repetition of this Mantra which is addressed to a certain Yakṣiṇī designated Vidyujjihvā (having a tongue resembling the lightning) is considered to have the power of revealing to one all the past and future events.

Beginning:

ओं करङ्कमुखे विद्युज्जिह्वे ओं भूं चटके जः जः ओं स्वाहा ।

नित्यमष्टोत्तरशतं जप्त्वा यत्किञ्चित्स्वात्मभोजनम् ।
तद्बलिं दीयते तस्यै वदानो मासमेकतः ॥

End:

अतीत्यानागतं कर्म स्वस्था स्वस्थं ब्रुवेत्तु सा ।
प्रतिमान् पर्वतान् सर्वान् चालयत्येव रक्षणात् ॥

No. 7224. विद्युज्जिह्वामन्त्रः.

VIDYUJJIHVĀMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 298*b* of the MS described under No. 5477, wherein it is found in the Mantramālikā 273*a* contained in the list of other works.

Complete.

Same as the above.

No. 7225. विद्युज्जिह्वामन्त्रः.

VIDYUJJIHVĀMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 99*b* of the MS. described under No. 5586, wherein this Mantra has been omitted to be included in the list of other works

Complete.

Same as the above.

No. 7226. विनायकाष्टाक्षरमन्त्रः.

VINĀYAKĀṢṬĀKṢARAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 29*b* of the MS described under No. 5786.

Complete.

The repetition of this Mantra consisting of eight syllables is intended to propitiate Vināyaka. The syllable Oṁ, occurring both in the beginning and in the end, is not to be taken as forming part of the Mantra

Beginning :

गुरुनमस्कारः । ओं क्षिप्रप्रसादाय नमः इति प्राणायामः (१२).

* * * *

अस्य श्रीविनायकाष्टाक्षरमन्त्रस्य कौशिको ब्रह्मा वा ऋषिः, गायत्री छन्दः, विनायको देवता ; विनायकप्रेरणया विनायकप्रीत्यर्थे जपे विनियोगः ।

End:

ओं क्षिप्रप्रसादाय नमः ओं इति जपः । उपसंहारः पूर्ववत् ॥

No. 7227. विभूतिमन्त्रः.

VIBHŪTIMANTRAḤ.

Pages. 3. Lines, 4 on a page.

Begins on fol 16*b* of the MS. described under No. 6600, wherein this Mantra has been omitted to be included in the list of other works.

Complete.

This Mantra is repeated by Śaivas while putting on the holy ashes.

Beginning:

अग्निरिति भस्म, वायुरिति भस्म, जलमिति भस्म, स्थलमिति भस्म, व्योमेति भस्म. . . . .

श्रीकरं च पवित्रं च रोगशोकनिवारणम् ।
लोकवश्यकरं पुण्यं भस्म त्रैलोक्यपावनम् ॥

End:

कर्णौ द्वौ शिवरुद्रं च कक्ष्यां चैव महेश्वरम् ।
बहिः कण्ठे पशुपतिं शिवश्श्रीरुद्रमेव च ॥

No. **7228.** विमुक्तबन्धनसुदर्शनमन्त्रः.

VIMUKTABANDHANASUDARŚANAMANTRAḤ.

Pages, 6. Lines, 6 on a page.

Begins on fol. 15*a* of the MS. described under No. 5822, wherein it is given as Vimuktabandhanamantra.

Complete.

This Mantra is addressed to Viṣṇu's "Discus," conceived as capable of going to any place whatsoever without any restraint for the accomplishment of desired objects.

Beginning:

अथ विमुक्तबन्धनमन्त्रः—

ओं नमो भगवते महोग्रदिग्विमुक्तबन्धनसुदर्शनाय अष्टादशबाहु-द्यु(ति)दिग्विमुक्तबन्धनाय महाज्वालामालाय ।

End:

ह्रीं ज्वालाचक्राय अधःपाताला(दि)दिग्विमुक्तबन्धनाय स्वाहा । श्रीं दीप्तचक्राय ऊर्ध्वप्रदेशादिग्विमुक्तबन्धनाय स्वाहा । भूर्भुवस्सुवरों ॥

Colophon:

इति दिग्विमुक्तबन्धः ॥

No. **7229.** विश्वरूपधरगोपालमन्त्रः.

VIŚVARŪPADHARAGŌPĀLAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 56*a* of the MS. described under No. 5885.

Complete.

The repetition of this Mantra is held to please Kṛṣṇa conceived as having assumed an all-comprehensive universal form.

Beginning:

अस्य श्रीविश्वरूपधरगोपालमन्त्रस्य नारद ऋषिः, गायत्री छन्दः, विश्वरूपधरगोपालो देवता ; अं कं खं गं घं ङं आं बीजं, इं चं छं जं झं ञं ईं शक्तिः, उं टं ठं डं ढं णं ऊं कीलकं, विश्वरूपधरगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

मनुः—

बिन्दुयुक्तपञ्चाशद्वर्णात्मकमन्ते कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ॥

No. 7230. विवाहगौरीमन्त्रः.

VIVĀHAGAURĪMANTRAḤ

Page, 1. Lines, 4 on a page.

Begins on fol. 1*a* of the MS. described under No. 5639.

Complete.

This Mantra is addressed to Pārvatī conceived as going through the ceremony of marriage with Paramaśiva.

Beginning:

अस्य श्रीविवाहगौरीमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीविवाहगौरी देवता, मम विवाहगौरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं कालि कालि . . . . . वन्नं देहि कुरु कुरु स्वाहा ॥

उमासन्निधौ लक्षजपसिद्धिः ॥

No. 7231. विषहरनारसिंहमालामन्त्रः.

VIṢAHARANĀRASIṀHAMĀLĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 57*a* of the MS. described under No. 5819, wherein it is given as Nārasiṁhamālāmantra

Complete.

The due repetition of this Mantra, which is in praise of Nṛsiṁha, is believed to be efficacious in removing the evil effect of poisons of various kinds and in counteracting the effects of hostile Mantras.

Beginning:

ओं नमो भगवते नारसिंहाय तीक्ष्णदंष्ट्राय बभ्रुकेसराय सर्वरोग-विनाशाय सर्वभयनिवारणाय ।

End:

सर्वविषदृष्टिविनाशाय परविद्याच्छेदनाय दह दह पच पच भक्षय भक्षय हुं फट् स्वाहा ॥

Colophon:

इति विषहरनारासिंहमन्त्रस्समाप्तः ॥

No. **7232.** विषहरमन्त्रः.

VIṢAHARAMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 302*b* of the MS. described under No. 5477, wherein it is found in the Mantramālikā 270*a* in the list of other works

Complete.

Similar to the above.

Beginning and **End:**

ओं ह्रीं ह्रीं ह्रूं वह्निवासिन्यै नमः ॥

Colophon:

इति सकलविषहरमन्त्रः ॥

ध्यानम्— पिङ्गाक्षि पीताम्बरधारिणि ऊर्ध्वकेशिनि उन्मत्तस्थानि त्रिशूलधारिणीति ॥

No. 7233. विषूचिकामन्त्रः.
VIṢŪCIKĀMANTRAḤ.

Substance, palm-leaf. Size, 15⅝ × 1⅛ inches. Pages, 3. Lines, 4 on a page. Character, Grantha. Condition, good. Appearance, old.

Begins on fol. 45*a*. The other works herein are Karmaprakāśika 1*a*, Vaṭuniyamavidhi 44*a*, Aśvatthastōtra 47*a*, Sōmavārāśvatthapūjāvidhi 50*a*.

Complete.

This Mantra is addressed to Viṣṇu's Śakti conceived as the presiding deity of cholera; and its repetition is believed to be efficacious in driving away cholera.

Beginning :

प्रविश्य हृदयं प्राणैः पञ्चप्लीहादिबाधनैः ।
वातलेखात्मको व्याधिर्भविष्यसि (ति) विषूचिका ॥

* * * *

गुणिनि त्वच्चिकित्सार्थं मन्त्रोऽयं तु मयोच्यते ॥

ओं ह्रां ह्रीं विष्णुशक्त्ये नमः । ओं नमो भगवति विष्णुशक्ति एह्येहि हर हर हन हन घन घन ।

End :

विषूचिके हिमवन्तं गच्छ यावच्चन्द्रमण्डलं गतोऽसि स्वाहा ॥
इति मन्त्री महामन्त्रं न्यस्य वामकरोदरे ।
मार्जयेदातुराकारं तेन हस्तेन संयतः ॥

* * * *

अथ प्रादेशमात्राङ्गी ततोऽप्यङ्गुलिरूपिणी ।
ततो माषश(षांशतु)लच्चा(सा)ततस्सूची बभूव सा ॥

No. 7234. विष्णुकवचः.
VIṢṆUKAVACAḤ.

Pages, 3. Lines, 8 on a page.

Begins on fol. 49*b* of the MS. described under No. 5786.

Complete; as found in the sixth Adhyāya of the Tulākāvērīmāhātmya which is dealt with in the Āgnēyapurāṇa.

the repetition of this Kavacamantra addressed to Viṣṇu is believed to be efficacious in securing protection and victory, in the curing of diseases and in the destruction of one's enemies, etc.

Beginning:

हरिश्चन्द्रः—

ब्रह्मन् श्रीविष्णुकवचं कीदृशं किंप्रभावकम् ।
केनोक्तं को मुनिश्छन्दो दैवतं कीदृशं मुने ॥

* * * *

पूर्वतो मां हरिः पातु पश्चाच्चक्री च दक्षिणे ।
कृष्ण उत्तरतः पातु श्रीशो विष्णुश्च सर्वशः ॥

End:

इदं श्रीविष्णुकवचं सर्वमङ्गलदायकम् ।
सर्वरोगप्रशमनं सर्वशत्रुप्रणाशनम् ॥
एवं जप्त्वा तु तत्काले ह्यात्मरक्षाकरं परम् ।
त्रिसन्ध्यं यः पठेच्छुद्धः सर्वत्र विजयी भवेत् ॥

Colophon:

इति श्रीमदाग्नेयपुराणे तुलाकावेरीमाहात्म्ये षष्ठाध्याये अगस्त्यहरिश्चन्द्रसंवादे श्रीविष्णुकवचस्तोत्रं सम्पूर्णम् ॥

No. 7235. विष्णुकवचः.

VIṢṆUKAVACAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 15*a* of the MS. described under No. 5938.

Complete.

Similar to the above.

Beginning:

अस्य श्रीविष्णुकवचस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीमहाविष्णुः परमात्मा देवता; ओं बीजं, लक्ष्मीश्शक्तिः, नमः कील(कं), मम सर्वाभीष्टसिद्ध्यर्थे वि(नि)योगः । . . . .

* * * *

पादौ रक्षतु गोविन्दो गुल्फे रक्षेज्जनार्दनः ।
जङ्घे रक्षेद्धरिः पातु जान्वो रक्षेत्त्रिविक्रमः ॥

End:

भुवनं चतुर्दशं दिव्यं वैनतेयेन रक्षितम् ।
पूर्वायां पुण्डरीकाक्ष आग्नेय्यां माधवस्तथा ॥
दक्षिणे नारसिंहश्च . . . . ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
विष्णुलोकं स गच्छत्यों नम इति ॥

Colophon:

इति श्रीविष्णुकवचं संपूर्णम् ॥

No. **7236**. विष्णुपञ्जरमन्त्रः.
VIṢṆUPAÑJARAMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 99*b* of the MS. described under No. 3680, wherein it is wrongly stated as beginning on fol. 99*a*.

Complete.

Similar to the above.

Beginning:

विष्णुपञ्जरमाहात्म्यं सर्वदुःखनिवारणम् ।
उग्रं तेजो महावीर्यं सर्वशत्रुनिकृन्तनम् ॥
त्रिपुरे दह्यमाने तु हरेण ब्रह्मणात्मनः ।
तदर्थं सम्प्रवक्ष्यामि आत्मरक्षासुखावहम् ॥

पादौ रक्षतु गोविन्दो जङ्घे पातु त्रिविक्रमः ।
ऊरू मे केशवः पातु कटिं दामोदरोऽवतु ॥

End:

जले रक्षतु वाराहस्तले रक्षतु वामनः ।
अटव्यां नारसिंहोऽपि सर्वतः पातु केशवः ॥

Colophon:

विष्णुपञ्जरं सम्पूर्णम् ॥

No. **7237.** विष्णुपञ्जरमन्त्रः.
VIṢṆUPAÑJARAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 191*a* of the MS. described under No. 5661.

Complete; as found in the Brahmāṇḍapurāṇa.

The repetition of this Mantra, which is also addressed to Viṣṇu, is believed to have the power to secure protection to one from all kinds of dangers. Some of the good results believed to be due to the repetition of this Mantra are given in the last stanza.

Beginning:

अस्य श्रीविष्णुपञ्जरस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, ईश्वरो देवता, मम शरीरसंरक्षणार्थे जपे विनियोगः ।

* * * *

पादौ रक्षतु गोविन्दो जङ्घे पातु त्रिविक्रमः ।
ऊरू(ममा)च्युतो रक्ष(क्षेत) गुह्यं रक्षतु माधवः ॥

End:

विष्णुपञ्जरसंयुक्तो विचरेच्च महीपतिः ।
राजद्वारे बिलद्वारे प्रदेशे भूतसङ्कुले ॥

* * *

अपुत्रो लभते पुत्रं धनहीनो लभेद्धनम् ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥

Colophon :

इति ब्रह्माण्डपुराणे त्रिपुरदहनकाले पार्वतीपरमेश्वरसंवादे श्रीविष्णुपञ्जरस्तोत्रं सम्पूर्णम् ॥

No. **7238.** विष्णुपञ्जरमन्त्रः.

VIṢṆUPAÑJARAMANTRAḤ.

Pages, 2. Lines, 21 on a page.

Begins on fol. 10*a* of the MS. described under No. 2373, wherein it has been omitted to be included in the list of other works given therein.

Complete.

Similar to the above

Beginning :

पादौ मे पातु गोविन्दः जङ्घे चापि त्रिविक्रमः ।
ऊरू च केशवो रक्षेत् कटिं चैव जनार्दनः ॥
नाभिं तु भार्गवो रक्षेत् गुह्यं रक्षतु वामनः ।

End :

सन्नतं सर्वगात्रेषु प्रविष्टो विष्णुपञ्जरम् ॥
पञ्जरश्च प्रविष्टोऽभूत् विचरामि महीतले ।
नदीतटे महारण्ये चोरव्याघ्रभयेषु च ॥
डाकिनीभूतबेताले भयं नास्ति कदाचन ।
रोगार्तो मुच्यते रोगात् स नरश्श्रियमाप्नुयात् ॥

No. **7239.** विष्णुपञ्जरमन्त्रः.

VIṢṆUPAÑJARAMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 1*a* of the MS. described under No. 2190, wherein it is given as Viṣṇupañjarakavaca.

Complete.

Same as the work described under number 6473.

No. 7240. विष्णुमन्त्रः—न्याससहितः.

VIṢṆUMANTRAḤ WITH NYĀSA.

Pages, 5. Lines, 21 on a page.

Begins on fol. 8*a* of the MS. described under No. 2373, wherein it has been omitted to be included in the list of other works.

Complete.

This Mantra is addressed to Viṣṇu. Preliminary to the repetition of this Mantra, the touching of the various parts of one's body, repeating the several names of Viṣṇu, is enjoined.

Beginning:

अव्यग्रचित्तः कुर्वीत न्यासकर्म यथाविधि ।
करन्यासं पुरा कृत्वा ततोऽङ्गन्यासमाचरेत् ॥
अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् ।
मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् ॥

End:

मनुः—
ओं नमो विष्णवे केशवाय सर्वक्लेशापहर्त्रे नमः ॥
अष्टोत्तरं वा सहस्रं वा जपं कुर्यात् ।
पञ्चोपचारान् कृत्वा एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् ॥

No. 7241. विष्णुषडक्षरमन्त्रः.

VIṢṆUṢAḌAKṢARAMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 7*b* of the MS described under No. 5786.

Complete.

The repetition of this Mantra consisting of six syllables is intended to secure the favour of Viṣṇu.

Beginning :

अथ विष्णुषडक्षरमन्त्रः—

ओं विष्णवे नमः इति प्राणायामः १२.

*   *   *   *

अस्य श्रीविष्णुषडक्षरमन्त्रस्य अन्तर्यामी ऋषिः, दैवीं गायत्री छन्दः, श्रीविष्णुर्देवता ; श्रीविष्णुप्रेरणया श्रीविष्णुप्रीत्यर्थे श्रीविष्णुषडक्षरमन्त्रजपे विनियोगः ।

End :

ओं विष्णवे नमः—इति जपः । उपसंहारः पूर्ववत् ॥

Colophon :

इत्यष्टमहामन्त्रजपः सम्पूर्णः ॥

No. **7242.** विष्णुषडक्षरमन्त्रः.

VIṢṆUṢAḌAKṢARAMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 37*a* of the MS. described under No. 3056.

Complete.

Similar to the above.

Beginning :

अस्य श्रीविष्णुषडक्षरमहामन्त्रस्य ब्रह्मा ऋषिः, देवी गायत्री छन्दः, श्रीमहाविष्णुर्देवता ; ओं बीजं, नमश्शक्तिः, श्रीं कीलकं, श्रीविष्णुप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षस्स्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ॥

मन्त्रः—
ओं नमो विष्णवे ॥

No. 7243. विष्णुषडक्षरमन्त्रः.
VIṢṆUṢAḌAKṢARAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 12*a* of the MS. described under No. 3546, wherein it is given as Viṣṇuṣaḍakṣarīmantranyāsa

Complete.

Similar to the above.

Beginning:

अस्य श्रीविष्णुषडक्षरमहामन्त्रस्य ब्रह्माद्यास्सनकाद्या ऋषयः, दैवी गायत्री छन्दः, परमात्मा देवता; अं बीजं, उं शक्तिः, अं कीलकं, श्रीमहाविष्णुप्रीत्यर्थे जपे विनियोगः ।

End:

विष्णुं श्यामलचन्द्रकोटिसदृशं शङ्खं रथाङ्गं गदा-
मम्भोजं दधतं सिताब्जनिलयं कान्त्या जगन्मोहनम् ।
आबद्धाङ्गदहारमौक्तिकरमाशोभास्फुरद्वक्षसं
श्रीवत्साङ्कमुदारकौस्तुभधरं वन्दे मुनीन्द्रावृतम् ॥
ओं ॥

No. 7244. विष्णुसूक्तमन्त्रः.
VIṢṆUSŪKTAMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 15*b* of the MS. described under No. 5786

Complete.

This Mantra in is in praise of Viṣṇu. It consists of 6 Ṛks in the 154th Sūkta of the 1st Maṇḍala of the Ṛgvēda

Beginning:

ओं विष्णवे नमः ओं इति प्राणायामः (१२).
पूर्णज्ञानेत्यादिन्यासः ।

अस्य श्रीविष्णुसूक्तमहामन्त्रस्य दीर्घतमा ऋषिः, त्रिष्टुप् छन्दः, श्रीविष्णुर्देवता ; श्रीविष्णुप्रेरणया विष्णुप्रीत्यर्थे विष्णुषडर्चसूक्तमहामन्त्र-जपे विनियोगः ।

End:

यत्र गावो भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य वृष्णः ।
परमं पदमवताति भूरि—इत्यन्तं जपः । उपसंहारः पूर्ववत् ॥

No. 7245. विष्णुसूक्तमन्त्रः.
VIṢṆUSŪKTAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 16*a* of the MS. described under No. 5786, wherein it has been omitted to be included in the list of other works given therein.

Complete.

The Mantra here consists of 6 Ṛks in the 154th, 6 Ṛks in the 155th, and 5 Ṛks in the 156th Sūkta of the 1st Maṇḍala of the Ṛgvēda.

Beginning:

अथवा विष्णोर्नुकमित्यारभ्य ऋतस्य भागे यजमानमाभजत् इत्यन्तं वर्गत्रयात्मकम् ।

End:

द्वितीयस्य जगती छन्दः । उपसंहारः पूर्ववत् ॥

No. 7246. विसर्गमातृकान्यासः.
VISARGAMĀTṚKĀNYĀSAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 193*a* of the MS. described under No. 124, wherein it is found in Daśavidhamātṛkanyāsa 192*a* in the list of other works.

Complete.

On the ceremonial touching of certain parts of the body while uttering the series of Mantra-formulas obtained by introducing the

successive letters of the alphabet followed by Visarga between the words ओं and नमः.

Beginning:

अथ विसर्ग[बिन्दु]मातृकान्यासः --

अस्य श्रीविसर्गमातृकान्यासमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीविसर्गमातृका सरस्वती देवता; व्यञ्जनानि बीजानि, स्वराश्शक्तयः, व्यक्तयः कीलकं, विसर्गमातृकान्यासे विनियोगः ।

End:

ओं अः नम इति क्षान्तं न्यसेत् ॥

Colophon:

इति विसर्गमातृकान्यासः ॥

No. 7247. विसर्गमातृकासरस्वतीमन्त्रः.

VISARGAMĀTṚKĀSARASVATĪMANTRAḤ.

Page, 1. Lines, 4 on a page.

Begins on fol. 139*a* of the MS. described under No. 537. The other works therein referred to are Dēvīmāhātmya 1*a*, Kātyāyanītantra 57*b*, Lalitāstōttaraśatanāman 64*a*, Tripurasundarītattvavidyāmantrasahasranāman 66*a*. Śūlinīmantra 75*a*, Pratikriyāstōtra 75*a*, Dēvīsūktamālāmantra 78*b*, Mahālakṣmīpūjā 80*b*, Pañcasiṁhāsanēśvarī with Sūkta 84*a*, Mahātripurasundarī, mantraśēṣa 87*b*. Śrīvidyāratnasūtra 90*a*, Śaktipratyaṅgirāmālāmantra 93*a*. Bālāsahasranāman 97*a*, Bagalāmukhīstōtra 103*a*, Bhuvanēśvarīstōtra 106*a*, Āsurīmantra 107*b*, Lalitātriśatī 109*a*, Rājyalakṣmīstōtra 11?*a*, Gurupādukāmantra 113*a*. 135*b* and 144*a*, Prāsādaparāparāprāsādamantra 115*a*. Dēvīpūjāvidhāna 118*a*, Bālātripurasundarīmantra 130*b*, 145*b* and 222*a*, Bagalāmukhīpūjāvidhāna 131*b*, Vārāhīmantra 135*a* and 244*a*, Mahāpādukāmantra 135*a*, Pārvatīmantra 135*a*, Kālikāmantra 136*a*, Sāmbadakṣiṇāmūrtimantra 136*b*. Rājarājēśvarīmahātripurasundarīmantra 137*a*, Āpaduddhāraṇavaṭukabhairavamantra 137*b*, Śuddhamātṛkāsarasvatī 138*b*, Bindumātṛkāsarasvatī 138*b*, Hṛllēkhāsarasvatī

139a, Yuktamātṛkāsarasvatī 139b, Bālāsampuṭitamātṛkāsarasvatī 139b, Parāsampuṭitamātṛkāsarasvatī 140a, Vidyāsampuṭitamātṛkāsarasvatī 140b, Ajapāmātṛkāsarasvatī 140b, Parāprāsādamantra 141b, Ajapāgāyatrī 142a and 250a, Pañcamayāgavidhi 145b, Dīpinīmantra 156a, Dēvīmālāmantra 156b, Ucchiṣṭagaṇapatimantra 158a, Mēdhādakṣiṇāmūrtimantra 158a and 167a, Śrīvidyāmantra 159a, Prāṇapratiṣṭhā 150 and 244a, Antarmātṛkāsarasvatī 160b, Bahirmātṛkāsarasvatī 161a, Kuṅkumamātṛkāsarasvatī 162b, Mahāgaṇapatimantra 163b and 168a, Bagalāmukhīmālāmantra 163b, Tiraskariṇīmantra 164b, Tārakabrahmamantra 165a, Cintāmaṇisarasvatī 165a, Mahālakṣmīmantra 165b, Bhuvanēśvarī mantra 165b, Tvaritāpārvatīmantra 166b, Śābaramantra (Hindustāni) 169a, Lalitāsahasranāmamahiman 170a, Dakṣiṇāmūrtikavaca 173a, Dakṣiṇāmūrtyaṣṭaka 175a, Dakṣiṇāmūrtiyantra 176a, Dakṣiṇāmūrtyupaniṣad 176b, Nīlakaṇṭhabaḍabānala 179a, Bhairavamālāmantra 179b, Indrākṣistōtramantra 18? and 183a, Indrākṣīyantra 182a and 183b, Dakṣiṇāmūrtyaṣṭōttaraśatanāman 185a, Caraṇavyūha 187a, Śarabhasāluvadvātriṁśadakṣarīmantra 191a, Śarabhasāluvamantrarājamahāmantra 191a and 191b, Śarabhasāluvamālāmantra 192a, Śarabhacitkalākarṣaṇamālāmantra 192b, Śarabhasāluvapakṣirājamālāmantra 194a, Śarabhamālāmantra 195a, Dakṣiṇāmūrtivyākhyā 196a, Vīraśarabhasāluvamantra 211a, Sudarśanamālāmantra 212a, Narasiṁhamālāmantra 212b, Pañcavaktrahanumatstōtramantra 213b, Hanumadbaḍabānalamantra 215a, Vīrabhadrakavaca 216a, Hanumanmantra 219a, Aghōrāstramantra 220b, Svarṇākarṣaṇabhairavamantra 221a, Saṁvicchūlinīmantra 224b, Garuḍapañcāśat 224b, Brahmasudarśanamantra 226a, Sudarśanakavaca 227a, Baḍabānalasudarśana 231b, Aghōrasudarśana 232b, Nṛsiṁhasahasrākṣarī 234a, Sudarśanamālāmantra 234a and 237a, Hanumanmālāmantra 239b, 240b and 243a, Śrīrāmastōtra 241a, Piṇḍapiśācī 245a, Bālākavaca 246a, Bālāhṛdaya 247a, Bālāmālāmantra 248a, Bālāstavarāja 248b, Gāyatrīnāmāvana 254a, Ṣōḍaśanāmadhyāna 256a, Śivavēdapādastava 259a, Dakṣiṇāmūrtyaṣṭaka 268a and b, Vīraśarabhamālāmantra 271a, Bhasmanyāsa 272a, Āndhrapadyamulu 274a, Navaratnamālikā 276a, Dēvīstava 277a, Mallikārjunastava 279a,

Ēkāmrēśvarāṣṭaka 279b, Bilvāṣṭaka 280b, Pārvatīparamēśvarāṣṭaka 281a, Mahādēvīstōtra 281b, Dēvīkavaca 283a

Complete.

Similar to the above.

This Nyāsa is intended to be a preliminary performance in relation to the repetition of the Śrīvidyāmantra.

Beginning:

अस्य श्रीविसर्गमातृकासरस्वतीमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, विसर्गमातृका सरस्वती देवता ; हलो बीजानि, स्वराश्शक्तय , बिन्दवः कीलकं, ममोपास्यमन्त्रश्रीविद्याङ्गत्वेन विसर्गमातृकान्यासे विनियोगः ।

End:

ओं ह्रीं श्रीं अः नमः —इति क्षः नमः पर्यन्तम् ॥

No. 7248. वीणाश्यामलामन्त्रः.

VĪṆĀŚYĀMALĀMANTRAḤ

Page, 1. Lines, 6 on page.

Begins on fol 3b of the MS. described under No. 673, wherein it is included in the Ṣaḍāmnāya 1a in the list of other works

Complete.

The repetition of this Mantra is intended to propitiate the goddess Śyāmalā, who is the same as Dēvī, and is believed to have the power to enable one to become proficient in the art of music.

Beginning:

अस्य श्रीवीणाश्यामलामन्त्रस्य मतङ्ग ऋषिः, अनुष्टुप् छन्दः, वीणाश्यामला देवता ; क्लीं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, वीणाश्यामलाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—ऐं ह्रीं श्रीं ओं नमो भगवति वीणाम्बे मम सङ्गीतविद्यां प्रयच्छ स्वाहा ॥

No. 7249. वीणाश्यामलामन्त्रः.
VĪṆĀŚYĀMALĀMANTRAḤ.

Page, 1. Lines, 10 on a page

Begins on fol. 229*a* of the MS. described under No. 124, wherein it is found in the Ṣaḍāmnāyamantra 228*b* in the list of other works.

Complete.

Similar to the above.

Beginning :

अस्य श्रीवीणाश्यामलामन्त्रस्य मतङ्ग ऋषिः, अनुष्टुप् छन्दः, वीणा देवता, वीणाश्यामलाप्र—गः ।

End :

ओं नमो भगवति विं वीणायै मम सङ्गीतविद्यां प्रयच्छ स्वाहा । सङ्गीतश्यामलाम्बादिव्यश्रीपादुकां पूजयामि ॥

No. 7250. वीरदशकमन्त्रः.
VĪRADAŚAKAMANTRAḤ.

Pages, 2. Lines, 17 on a page.

Begins on fol. 5*b* of the MS. described under No. 5673, wherein this Mantra is found in the Āmnāyamantramālikā 1*a* in the list of other works.

Complete.

The repetition of this Mantra is considered to have the power to propitiate the following ten Vīra-bhairavas who are looked upon as Śākta-gurus :—

(1) Sṛṣṭivīrabhairava, (2) Sthitivīrabhairava, (3) Saṁhāravīrabhairava, (4) Raktavīrabhairava, (5) Yamavīrabhairava, (6) Mṛtyuvīrabhairava, (7) Bhadravīrabhairava, (8) Paramārkavīrabhairava, (9) Mārtāṇḍavīrabhairava, (10) Kālāgnirudrabhairava.

Beginnnig :

अस्य श्रीवीरदशकमन्त्रस्य परमानन्दभैरव ऋषिः, गायत्री छन्दः, श्रीदशवीरभैरवो देवता ; ओं बीजं, ह्रीं शक्तिः, हं (फं) कीलकं, मम श्रीवीरदशकप्रसादसिद्ध्यर्थे विनियोगः ।

End:

मनुः—

ह्रीं श्रीं फं फां फीं सृष्टिवीरभैरवश्री ५, स्थितिवीरभैरवश्री ५, संहारवीरभैरवश्री ५, ... कालाग्निरुद्रवीरभैरवश्री ५, १४ ॥

No. 7251. वीरदशकमन्त्रः.
VĪRADAŚAKAMANTRAḤ.

Pages, 2. Lines, 4 on a page.

Begins on fol. 23*a* of the MS. described under No. 2848, wherein it is found in the Pūrvāmnāyamantramālikā 16*a*.

Complete.

Same as the above.

No. 7252. वीरदारणनारसिंहमालामन्त्रः.
VĪRADĀRAṆANĀRASIṀHAMĀLĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 1*b* of the MS. described under No. 5828, wherein this Mantra has been omitted to be included in the list of other works given therein.

Incomplete.

This Mantra praises, under various significant names, Nṛsiṁha who tore to pieces the valiant Hiraṇyakaśipu.

Beginning:

ओं नमो भगवते अघोरवीरदारणनारसिंह(ाय)रौद्राग्निज्वलितनेत्रत्रयाय प्रलयकालाग्निरुद्रावतारा(य)ज्वालानारसिंहा(य).

End:

ज्वालय ज्वालय महानारसिंह ख ख रञ्जित रञ्जित स्तम्भोत्स्फूर्जित घगघगित.

No. 7253. वीरनृसिंहमन्त्रः.
VĪRANṚSIṀHAMANTRAḤ.

Pages, 12. Lines, 5 on a page.

Begins on fol. 9*b* of the MS. described under No. 6387, wherein it is apparently wrongly stated as beginning on fol. 9*a* in the list of other works.

Complete as found in the Mārkaṇḍēya-purāṇa.

This Mantra also praises Nṛsiṁha under various significant names.

Beginning :

अस्य श्रीवीरनृसिंहकेसरिप्रभापटलबकमन्त्रस्य अघोरनृसिंहकोटिसूर्य-प्रकाशम्य श्रीज्वालानृसिंहदिव्यमन्त्रो देवता, अनुष्टुप् छन्दः, ओं नमो भगवते दिव्यनृसिंहसुदर्शनाय कालाग्निरुद्राय हुङ्कृतविजयशौर्यमहाबल-पराक्रमाय सहस्रभुजशङ्खचक्रगदाधरवज्रदंष्ट्राकरालाय.

End :

ह्रां ह्रीं ह्रूं ह्रें ह्रैं ह्रों ह्रौं ह्रः क्षां क्षीं क्षूं क्षें क्षैं क्षों क्षौं क्षः द्रां द्रीं द्रुं फट् स्वाहा ॥

Colophon :

इति मार्कण्डेयपुराणे वीरनृसिंहमालामन्त्रः संपूर्णः ॥

No 7254. वीरनृसिंहमन्त्रः.

VĪRANṚSIṀHAMANTRAḤ.

Pages, 18. Lines, 5 on a page.

Begins on fol. 1*a* of the MS. described under No. 5836.

Complete.

Same as the above.

No. 7255. वीरप्रचण्डहनुमन्मालामन्त्रः.

VĪRAPRACAṆḌAHANUMANMĀLĀMANTRAḤ.

Pages, 15. Lines, 6 on a page.

Begins on fol. 44*b* of the MS described under No. 5822.

Complete.

This Mantra is addressed to Hanumat who is conceived as a very valiant and awe-inspiring deity.

Beginning :

वीरप्रचण्डहनुमन्मालामन्त्रस्य शौनक ऋषिः, अतिजगती छन्दः, हनुमान् रुद्रो देवता; रां बीजं, फट् शक्तिः, हुं कीलकं, श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं ऐं क्लीं हुं ह्र ह्र ओं नमो भगवते वीरहनुमते

* * * *

ओं तपस्सत्यं ओं नमो भगवते रामदूतहनुमते वीर्यायास्त्राय फट् । भूर्भुवस्सुवरोमिति विमु(दि)क्बन्धः ॥

Colophon :

हनुमन्मालामन्त्रः समाप्तः ॥

No. **7256.** वीरप्रतापहनूमन्मन्त्रः.

VĪRAPRATĀPAHANŪMANMANTRAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 67*a* of the MS. described under No. 21.

Complete.

Similar to the above. The repetition of this Mantra is considered to have the power to enable one to accomplish one's desires.

Beginning :

अस्य श्रीवीरप्रतापहनूमन्महामन्त्रस्य ईश्वरः ऋषिः, जगती छन्दः, श्रीवीरप्रतापहनुमान् देवता, ह्रीं बीजं, फट् शक्तिः, स्वाहा कीलकं, मम वीरप्रतापहनुम — विनियोगः ।

End :

मनुः—श्रीं वीरहनुमन्ताय प्रतिभटशिरश्छेदनाय शरणागतवज्रपञ्जर मम सर्वकार्याणि साधय साधय हुं फट् स्वाहा । गायत्री—तत्पुरुषाय विद्महे रामभक्ताय धीमहि । तन्नः प्लवङ्गमः प्रचोदयात् ॥

No. 7257. वीरभद्रकवचः.
VĪRABHADRAKAVACAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 153*a* of the MS. described under No. 5661.

Complete.

This Kavaca-mantra is addressed to Vīrabhadra; and its repetition is considered to have the power to secure protection to one from all possible dangers and to be helpful in the accomplishment of one's desires

Beginning:

अस्य श्रीवीरभद्रकवचस्तोत्रमन्त्रस्य अत्रिभगवान् ऋषिः, अनुष्टुप् छन्दः, प्रसन्नवीरभद्रो देवता, मम इष्टकाम्यार्थसिद्ध्यर्थे जपे विनियोगः ।

* * * *

वीरभद्रोऽग्रतः पातु पृष्ठं पातु पिनाकभृत् ।
वक्षो(दक्षे)दक्षक्रतुध्वंसी वामदेवस्तु वामतः ॥

End:

श्रीवीरभद्रकवचं भक्तानां वज्रपञ्जरम् ।
यः पठेच्छृणुयान्नित्यं वीरभद्रप्रसादतः ॥
अन्तश्च वीरो बहिरेव वीरः पार्श्वश्च वीरः परितश्च वीरः ।
पृष्ठे च वीरः पुरतश्च वीरः सर्वत्र वीरस्सगणस्सहायः ॥

Colophon:

वीरभद्रकवचं संपूर्णम् ॥

No. 7258. वीरभद्रकवचः.
VIRABHADRAKAVACAḤ.

Pages, 6. Lines, 6 on a page.

Begins on fol. 216*a* of the MS. described under No. 537.

Complete.

Similar to the above.

Beginning:

अस्य श्रीवीरभद्रकवचस्तोत्रमन्त्रस्य पशुपतिः ऋषिः, विघ्नच्छन्दः, श्रीवीरभद्रो देवता; ओं बीजं, ह्रीं शक्तिः, श्रीं कीलकं,

* * * *

श्रीं वीरभद्रकवचं पूर्वदिशं बन्धयामि—रुद्रविश्वेश्वराय नमः, आग्नेयदिशं बन्धयामि—विष्फुलिङ्गवीरभद्राय नमः ।

End:

क्षां क्षीं क्षूं क्षें क्षों क्षौं क्षः त्रिशान्तवीरभद्राय त्रिशूलडमरुगपाशाङ्कुशधनुश्शरशस्त्रमुसलतोमरबाणाङ्कुशसकलशस्त्रास्त्रभूषणाय ओं ठं ठं ठं ठं हं हं हें हें हुं हुं फट् स्वाहा ॥

No. 7259. वीरभद्रबडबानलमन्त्रः.

VĪRABHADRABAḌABĀNALAMANTRAḤ.

Pages, 7. Lines, 5 on a page.

Begins on fol. 43*a* of the MS. described under No. 5836.

Complete.

The repetition of this Mantra is intended to propitiate Vīrabhadra conceived to be as terrible as the sub-marine fire known as Baḍabānala.

Beginning:

अस्य श्रीवीरभद्रबडबानलमन्त्रस्य ईशान ऋषिः, ककुत् छन्दः, श्रीवीरभद्रबडबानलरुद्रो देवता; ह्रीं बीजं, स्वाहा शक्तिः, वषट् कीलकं, मम श्रीवीरभद्रप्रीत्यर्थे विनियोगः ।

End:

ओं नमो भगवते प्रळयकालवीरभद्राय कुरु कुरु फट् स्वाहा ॥

No 7260. वीरभद्रबडबानलमन्त्रः.

VĪRABHADRABAḌABĀNALAMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 32*a* of the MS. described under No. 5422, wherein it has been wrongly given as Vīrabhadra-kavaca in the list of other works.

Complete.

Similar to the above.

The deity addressed here is Pralayakālavīrabhadra. and the repetition of this Mantra is held to be efficacious in safeguarding one's Mantras and in counteracting the effects of hostile Mantras, etc.

Beginning:

अस्य श्रीवीरभद्रबडबानलमहामन्त्रस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः, श्रीप्रलयकालवीरभद्रो देवता ; ओं बीजं, ह्रां कीलकं, मम श्रीप्रलयकालवीरभद्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं नमो भगवते प्रलयकालवीरभद्रावताराय अनेककालनिर्णाशनाय दक्षयज्ञविनाशनाय आत्ममन्त्रयन्त्रतन्त्ररक्षणाय परमन्त्रपरयन्त्रपरतन्त्रप्रच्छेदनाय आमुखु आमुखु कह कह अनेकमुद्राय ह्रां ह्रीं ह्रूं ह्रैं ह्रैं ह्रौं ह्रः फट् स्वाहा ॥

No. 7261. वीरभद्रबडबानलमन्त्रः.

VĪRABHADRABAḌABĀNĀLAMANTRAḤ.

Substance, palm-leaf. Size, 5⅝ × 1⅛ inches. Pages, 7. Lines, 5 on a page. Character, Telugu. Condition, good.. Appearance, old.

Begins on fol. 5*a*. The other works herein are Indrākṣīstōtra 1*a*, Śarabhasālvamantra 4*a*.

Complete.

Same as the above.

No. 7262. वीरभद्रबडबानलमन्त्रः.

VĪRABHADRABAḌABĀNALAMANTRAḤ.

Pages, 3. Lines, 8 on a page.

Begins on fol. 2*b* of the MS. described under No. 5828.

Complete.

This Mantra is addressed to Vīrabhadra conceived to be as terrible as the sub-marine fire known as Baḍabāgni; and its repetition is considered to be efficacious in bringing about the accomplishment of one's desires.

Beginning:

अस्य श्रीवीरभद्रबडबानलमन्त्रस्य विष्णुः ऋषि, अमृतगायत्री छन्दः, वीरभद्रेश्वरो देवता ; हुं बीजं, ह्रीं शक्तिः, मम इष्टकाम्यार्थसिद्ध्यर्थे वीरेश्वरप्रीत्यर्थे जपे विनियोगः ।

End:

कम्पय कम्पय स ह्रों हे वीरभद्र रुद्रे रौद्रावतार भक्तजननरक्षणाय श्रीं हूं फट् स्वाहा ॥

No. **7263.** वीरभद्रबडबानलमालामन्त्रः.

VĪRABHADRABAḌABĀNALAMĀLĀMANTRAḤ.

Pages, 4. Lines, 5 on a page.

Begins on fol. 17*a* of the MS. described under No. 6393.

Incomplete.

Similar to the above.

Beginning:

ओं ह्रां अघोरवीरसाराय, ह्रीं अरुणप्रभाकरप्रज्वलितकुण्डलधराय, ह्रूं अष्टादशभुजकलकिङ्किणीकरवराय, ह्रां शङ्खचक्रगदाधरत्रिशूलडमरुकधनुर्बाणहलमुसलपाशाङ्कुशकरवालकालसर्पघोरखट्वाङ्गकुलिशमुद्गरभिण्डिपालाद्यखिलायुधधराय, प्रलयकालाग्निरुद्ररौद्रवर्मज्योतिःप्रचण्डवीरभद्रबडबानलभैरवाय ।

End:

यं रं सं नं चतुर्वेदपरिपूर्णाय अनुत्त(म)मन्त्रमायावाद अभङ्गवेगगरुडवेगाय सर्वमन्त्रसर्वयन्त्रतन्त्ररक्षणाय सर्वपरमन्त्रयन्त्रतन्त्रच्छेदनाय.

No. **7264.** वीरभद्रबडबानलमालामन्त्रः.

VĪRABHADRABAḌABĀNALAMĀLĀMANTRAḤ.

Pages, 3. Lines, 18 on a page.

Begins on fol. 77*a* of the MS. described under No. 5673.

Complete.

Similar to the above.

Held to be efficacious in removing all kinds of evils and in securing the grace of Pralayakālavīrabhadra.

Beginning :

अस्य श्रीवीरभद्रबडबानलस्तोत्रमन्त्रस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः, श्रीप्रलयकालवीरभद्रो देवता ; ओं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, मम सर्वोपद्रवप्रहरणार्थसिद्ध्यर्थे श्रीप्रलयकालवीरभद्रप्रीत्यर्थे जपे विनियोगः ।

End :

क्ष म र व र र यीं ओं नमो भगवते प्रलयकालवीरभद्रावताराय ह्रीं ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा ॥

No. 7265. वीरभद्रमन्त्रः.

VĪRABHADRAMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 239*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 239*a* in the list of other works.

Complete.

This Mantra is addressed to Vīrabhadra created by Śiva for destroying the sacrifice performed by Dakṣa

Beginning :

अस्य श्रीवीरभद्रमन्त्रस्य उक्ता(नि) छन्दः (न्दांसि), . . . कृत्वा जपं करिष्ये । तत् मन्त्रं . . . मूलमन्त्रः—ओं नमो वीरभद्राय दक्षयज्ञविनाशनाय ।

End :

अज्ञनातनयमनोराञ्जिताय ह्रीं हुं फट् स्वाहा । अक्ष(र)लक्षपुरश्चरणं, मूलमन्त्रमेकाक्षरं जपेत् । दशांशहोमः ॥

No. 7266. वीरभद्रमन्त्रः.

VĪRABHADRAMANTRAḤ.

Pages, 2. Lines, 10 on a page.

Begins on fol. 91*b* of the MS. described under No. 5566, wherein it is wrongly stated as beginning on fol. 93 in the list of other works.

Complete.

Same as the above.

No. 7267. वीरभद्रमन्त्रः.

VĪRABHADRAMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 282*a* of the MS. described under No. 5477, wherein it is included in the Mantramālikā 273*a* given therein in the list of other works.

Complete.

Similar to the above Held to be efficacious in removing various kinds of evils.

Beginning and End:

अस्य श्रीवीरभद्रमन्त्रस्य उक्तानि छन्दांसि, वामदेव ऋषिः, श्रीसदाशिवरुद्रो देवता; भद्रकाली बीजं, ह्रीं शक्तिः, ममारिष्टनिर्हरणार्थे विनियोगः । सर्वत्र रुद्रगायत्रीजपः ॥

No. 7268. वीरभद्रमन्त्रः.

VĪRABHADRAMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 45*b* of the MS. described under No. 2886.

Complete.

Similar to the above.

Beginning:

वीरभद्रस्य कालरुद्रः, जगती, वीरभद्रः, विं बी, हुं श, नि- मद्दे ।

End:

ह्रां खं फट् च रिपून् फट् च स्वाहान्तं मन्त्रमुच्यते ॥
अक्षरसहस्रं जपः ।

ठकारमध्ये परिलिख्य मन्त्रं बाह्येऽष्टपत्रेषु च हुं फडर्णम् ।
संवेष्ट्य पाशाङ्कुशमातृकार्णमाराधयेच्छ्यामलवीरभद्रम् ॥

आराधनानन्तरं मातृकावर्णपूर्वकं जपेत् ॥

No. **7269.** वीरभद्रमालामन्त्रः.

VĪRABHADRAMĀLĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 53*b* of the MS. described under No. 5686

Complete.

The repetition of this Mantra, which is also addressed to Vīrabhadra, is held to be efficacious in driving away and destroying evil spirits, etc.

Beginning and **End:**

रौद्रं रुद्रावतारं हुतवहनयनं व्योमकेशं सुदंष्ट्रं
श्यामाङ्गं भीमरूपं भिणि भिणि रभसं ज्वालमालाहुताङ्गम् ।
भूतप्रेताधिनाथं कदनकलुषिते खड्गचर्मे वहन्तं
वन्दे लोकैकवीरं त्रिभुवनमहितं वीरभद्रं नमामि ॥

ओं प्रलयकालभूतबेतालभैरवाय भूतप्रेतपिशाचोच्चाटनाय स्वमन्त्र-यन्त्ररक्षणाय अष्टम(हा)भैरवाय शाकिनीः डाकिनीः छिन्धि छिन्धि सर्व-शक्तीः छिन्धि छिन्धि ह्रीं ह्रीं ठं फट् स्वाहा ॥

No. **7270.** वीरभद्रमालामन्त्रः.

VĪRABHADRAMĀLĀMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 20*a* of the MS. described under No. 6005.

Complete.

Similar to the above.

Beginning :

ओं वीरभद्राय द्र(द)क्षसंहरणाय आपदुद्धारणाय ईश्वरपुत्राय प्रलयाग्निरु(द्रावतार य) नरसिंहसंहारणाय ओं फट् स्वाहा ।

End :

ल ल ल ल लि लि ओं अघोरभद्राय नमः ओं फट् स्वाहा ॥

No. **7271.** वीरभद्रमालामन्त्रः.

VĪRABHADRAMĀLĀMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 31*a* of the MS. described under No. 6005.

Complete.

Same as the above.

No. **7272.** वीरलक्ष्मीमन्त्रः.

VĪRALAKṢMĪMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 5*a* of the MS. described under No. 6157.

Incomplete.

This Mantra is in praise of Vīralakṣmī, described with various significant attributes.

Beginning :

ओं ओं ओं ज्वल ज्वल अघोरवीरमन्त्रज्ञे बीजसङ्कलितमहाग्निबीजाक्षरि सङ्कलितसकलग्रहबन्धनि अष्टदिग्बन्धनि नानादिग्बन्धनि आकाशबन्धनि अन्तरिक्षबन्धनि अवनिबन्धनि.

End :

हा हूं ओं बीजाक्षरि रक्ताक्षि उग्ररूपि ओं ज्वालालक्ष्मि अघोरवीरलक्ष्मि ॥

No. **7273.** वीरशरभमन्त्रः.

VĪRAŚARABHAMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 281*a* of the MS. described under No. 5477, wherein it is included in the Mantramālikā 273 given therein in the list of other works.

Complete.

This Mantra is addressed te Rudra or Śiva, who, according to the Purāṇas, once assumed a peculiar beast-and-bird form to subdue the Nṛsiṁha (man-lion) incarnation of Viṣṇu; and its repetition is believed to enable one to accomplish the four Puruṣārthas or aims of life, viz., Dharma, Artha, Kāma and Mōkṣa.

Beginning:

अस्य श्रीवीरशरभमहामन्त्रस्य त्रिपुरान्तक ऋषिः, अनुष्टुप् छन्दः, त्रिपुरसंहारमहारुद्रो देवता; मम चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः ।

End:

ओं नमो भगवते महावीरशरभाय द्विशिरसे द्विनेत्राय द्विपक्षाय सपुच्छायाग्निवर्णाय मृगविहङ्गरूपाय श्रीवीरशरभाय नमः ॥

पूर्ववज्जपहोमः ॥

No. 7274. वीरशरभमन्त्रः.

VĪRAŚARABHAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 112*b* of the MS. described under No. 119.

Complete.

Similar to the above.

Beginning:

ओं ह्रीं शं शां नमो भगवते वीरशरभाय ज्वालामालिने दीप्तदंष्ट्राय अग्निनेत्राय सर्वरक्षोघ्नाय तत्पुरुषाघोरवामदेवसद्योजातेशानाय.

End:

मृगविहङ्गमरूपाय श्रीवीरशरभेश्वराय नमः ॥

Colophon:

श्रीवीरशरभेश्वरस्तोत्रं सम्पूर्णम् ॥

No. 7275. वीरशरभमन्त्रः.

VĪRAŚARABHAMANTRAḤ

Pages, 2. Lines, 27 on a page.

Begins on fol. 238*a* of the MS. described under No. 581, wherein it is found in the group of Mantras denoted by the

general name of Mantramālikā given therein in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीवीरशरभमहामन्त्रस्य अघोररूपो भगवानृषिः, अमृतगायत्री छन्दः, श्रीमहावीरशरभो देवता; श्वेतवर्ण, (उदात्तस्वरः,) (पर)-मात्मक्षेत्रं, हं बीजं, हुं शक्तिः, मं कीलकं, ममेष्टकाम्यार्थसिद्ध्यर्थे श्री-महाशरभेश्वरप्रीत्यर्थे विनियोगः ।

End:

ओं भूर्भुवस्सुवः पतये मृत्युपतये अमृतं मे प्रयच्छ स्वाहा । शां - शं । ओं लक्षजपपुरश्चरणं कुर्यात् । दशांशहोमः ॥

No. 7276. वीरशरभमन्त्रः.

VĪRAŚARABHAMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 91*b* of the MS. described under No. 5566, wherein it is given as Mahāvīraśarabhamantra and is wrongly, stated as beginning on fol. No. 92.

Complete.

Same as the above.

No. 7277. वीरशरभमन्त्रः.

VĪRAŚARABHAMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 280*b* of the MS. described under No. 5477, wherein it is found in the Mantramālikā 273*a* in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीवीरशरभमन्त्रस्य अघोररूपो भगवानृषिः, अमृतगायत्री छन्दः, श्रीमहावीरशरभो देवता; श्वेतवर्णः, उदात्तस्वरः, परमात्मक्षेत्रं,

हूं बीजं, हुं शक्तिः, मम कीलकं, ममेष्टकाम्यार्थसिद्ध्यर्थे श्रीमहावीर-शरभेश्वरप्रीत्यर्थे विनियोग ।

End :

कालाग्निरुद्राय कालकण्ठाय गरलसंहरणाय मृत्युपतये अमृतं मे प्रयच्छ स्वाहा । शां शं ॥

ओं लक्षजपं दशांशहोमः ॥

No. 7278. वीरशरभमालामन्त्रः.
VĪRAŚARABHAMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 211a of the MS. described under No. 537.

Complete.

This Mantra is in praise of Śiva under various significant names.

Beginning :

अस्य श्रीशरभसाल्वमन्त्रस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः, श्रीवीर-शरभसाल्ववीरभद्रो देवता, ओं बीजं, स्वाहा शक्तिः, जें कीलकं, श्री-शरभसाल्वप्रीत्यर्थे जपे विनियोगः ।

End :

नृसिंहशिरश्छेदनाय अरिष्टशत्रुसंहरणाय मृगपक्षिरूपाय जय जय श्रीमहावीरवीरशरभसाल्वपक्षिराजाय हुं फट् स्वाहा ॥

No. 7279. वीरशरभमालामन्त्रः.
VĪRAŚARABHAMĀLĀMANTRAḤ.

Page, 1. Lines, 4 on a page.

Begins on fol. 271a of the MS. described under No. 537.

Complete.

Similar to the above.

Beginning:

भस्मोद्धूलितदेहानामापादतलमस्तकम् ।
रोमरोम भवेल्लिङ्गं तद्देहं शिवमुच्यते ॥

ओन्नमो भगवते वीरशरभाय तीक्ष्णदंष्ट्राकरालाय त्रिनेत्राय ज्वल ज्वल प्रज्वलय.

End:

शत्रुसंहाराय प्रळयकालवीरशरभाय असाध्यसाध्याय ह्रां ह्रीं ह्रूं हुं फट् स्वाहा ॥

No. 7280. वीरहनुमन्मालामन्त्रः.
VĪRAHANUMANMĀLĀMANTRAH.

Page, 1. Lines, 19 on a page.

Begins on fol. 21*a* of the MS. described under No. 2886.

Complete.

This Mantra is in praise of Hanumat under various significant names. Its repetition is held to have the power to safeguard one from the evils that may come from the various quarters as also from the evils caused by evil spirits.

Beginning:

ओन्नमो भगवते महावीरप्रतापमहाबलपराक्रमाक्रान्ताय वज्रदेहस्व-रूपाय वैदेहीहृदयशोकविनाशनाय अञ्जनागर्भसंभूताय ।

End:

सर्वग्रहबन्धनाय सर्वदिग्बन्धनाय ओन्नमो भगवते हुं फट् स्वाहा । वीरहनूमते हुं फट् स्वाहा ॥

No. 7281. वीरहनुमन्मालामन्त्रः.
VĪRAHANUMANMĀLAMANTRAH

Pages, 4. Lines, 6 on a page.

Begins on fol. 23*a* of the MS. described under No 5828.

Incomplete.

Similar to the above.

Held to be efficacious in the accomplishment of one's desires, in driving off all kinds of evil spirits, and in removing various kinds of fever.

Beginning :

अस्य श्री(वीर)हनुमन्ताघोरप्रलयज्वालारौद्रविजयविद्रुमवीरहनुमन्ता-साध्यसाधनाघोरास्त्रप्रयोगमूलमन्त्रस्य वामदेव ऋषिः, गायत्रीच्छन्दः, ओं बीजं, स्वाहा शक्तिः, ह्रं कीलकं, श्रीवीरहनुमान्देवता, इष्टकाम्यार्थफल-सिद्ध्यर्थे जप विनियोगः ।

End :

ओं नमो भगवते प्रतापहनूमते भूतप्रेतपिशाचमण्डलदानवदैत्यब्रह्म-राक्षसवेतालमण्डल . . . उच्चाटनाय तद्वत् ग्रहज्वरमाहेश्वरज्वरत्रिरात्र-ज्वरचातु(र)र्थिकज्वर.

No 7282. वीरहनुमन्मालामन्त्रः.

VĪRAHANUMANMĀLĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 16 of the MS. described under No 5828, wherein this Mantra has been omitted to be included in the list of other works given therein.

Complete.

Similar to the above.

Held to be efficacious in enabling a person to free himself from bondage of all kinds.

Beginning and **End :**

ओं नमो भगवते वीरहनुमन्ताय हं हां ह्रीं ह्रीं हूं . . . . तापिपराक्रमाय एहि एहि मम बन्धमोचनाय . . . . हुं फट् स्वाहा ॥

Colophon :

वीरहनुमन्तं(न्मालामन्त्रः) ॥ पुरश्चरणम् १० ॥

No. 7283. वीरहनुमन्मालामन्त्रः.
VĪRAHANUMANMĀLĀMANTRAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 67*a* of the MS. described under No. 21, wherein it is given as Vīrapratāpahanumanmālāmantra in the list of other works.

Complete.

Similar to the above.

Held to be efficacious in the accomplishment of one's desires

Beginning:

ओं नमो (वीर)हनूमन्त प्रकटपराक्रमाक्रान्तदशादिङ्मण्डल यशो- वितानधवलीकृतजगत्त्रितय वज्रदेह रुद्रांशसंभव ।

End:

लक्ष्मणप्राणसंरक्षण कुमारब्रह्मचारिन् रामप्रियतम दशास्यदर्पदलन मह्यं सर्वकार्याणि साधय साधय हुं फट् स्वाहा ॥

No. 7284. वीरावलीमन्त्रः.
VĪRĀVALĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 233*a* of the MS. described under No. 124, wherein it is found in the Ṣaḍāmnāyamantra 2286 given therein in the list of other works.

Complete.

This Mantra is addressed to the five following groups of attendants of the goddess Śakti. They are considered also as Śākta-gurus:—

(1) Brahmavīrāvalī, (2) Viṣṇuvīrāvalī, (3) Rudravīrāvalī, (4) Īśvaravīrāvalī, (5) Sadāśivavīrāvalī

Beginning:

अस्य श्रीवीरावलीमन्त्रस्य ब्रह्मविष्णुरुद्रेश्वरसदाशिव(।) ऋषयः, गायत्री छन्दः, वीरावली देवता ; लं वं रं यं हं बीजानि, सरस्वती महालक्ष्मी

पार्वती उन्मनी मनोन्मनी शक्तयः, सो हं कीलक, मम श्रीवीराव-
लीप्र—गः ।

End:

ऐं ह्रीं श्रीं ऐं क्लीं सौः ब्रह्मवीरावलीदिव्यश्री—-मः, विष्णुवीरा-
वलीदि, रुद्रवीरावलीदि, ईश्वरवीरावलीदि, सदाशिववीरावलीदिव्यश्री—-
मः, नवमुद्रावीरावलीयुक्ताय द्विसहस्रदेवतासाहिताय ओड्याणपीठदिव्य-
श्री—-मः ॥

No. 7285. वीरावलीमन्त्रः.

VĪRĀVALĪMANTRAḤ.

Pages, 2 Lines, 18 on a page.

Begins on fol. 7a of the MS. described under No. 5673, wherein it is found in the Āmnāyamantramālikā 1 / in the list of other works.

Complete

Similar to the above.

See under the previous number for the beginning.

End:

सदाशिववीरावलीश्रीपादुकां पूजयामि नमः । इत्युत्तराम्नायगुरून्
हृदये मत(न)श्चक्रे च पूजयेत् ॥

No. 7286. वीरावलीमन्त्रः.

VĪRĀVALĪMANTRAḤ.

Page, 1. Lines, 4 on a page.

Begins on fol. 26 of the MS described under No. 2848, wherein it is found in the Pūrvāmnāyamantramālikā 16a given therein in the list of other works.

Complete

Similar to the above.

Beginning:

पञ्चवीरावलीमन्त्रस्य ब्रह्मविष्णुरुद्रेश्वरसदाशिवा ऋषयः, वीरावली
देवता; लं वं रं यं हं बीजं, वाणी महालक्ष्मीः उमा पार्वती मनो-
न्मनी शक्तिः, सो हं कीलकं, विनियोगः ।

End:

ऐं ह्रीं श्रीं ऐं क्लीं सौः ब्रह्मवीरावली श्रीविष्णुरुद्रेश्वरसदाशिवाः ॥

No 7287. वीरावलीमन्त्रः.

VĪRĀVALĪMANTRAH.

Page, 1. Lines, 6 on a page.

Begins on fol. 7*a* of the MS described under No. 673.

Complete.

Similar to the above.

Beginning:

अस्य श्रीपञ्चवीरावलीमन्त्रस्य ब्रह्मविष्णुरुद्रेश्वरसदाशिव(ा) ऋषि(षय)ः, गायत्र्यादीनि छन्दांसि, पञ्चवीरावली देवता; लं वं यं रं हं बीजानि, वाणी लक्ष्मीः उमा भवानी मनोन्मनी देवता शक्तयः, सो हं कीलकं, मम वीरावलीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

रुद्रवीरावलीश्री, ईश्वरवीरावलीश्रीपा, सदाशिववीरावलीश्री, पञ्चवीरावलीश्रीपा—नमः ।

No. 7288. वेणुनादगोपालमन्त्रः.

VĒṆUNĀDAGŌPĀLAMANTRAH.

Pages, 2. Lines, 5 on a page.

Begins on fol. 46*b* of the MS. described under No. 5885.

Complete.

This Mantra is addressed to Kṛṣṇa, conceived as a cowherd playing on a flute; and its repetition is intended to please him.

Beginning:

अस्य श्रीवेणुनादगोपालमन्त्रस्य नारद ऋषिः, गायत्री छन्दः, श्रीवेणुनादगोपालो देवता, क्लां बीजं, क्लीं शक्तिः, क्लूं कीलकं, श्रीवेणुनादगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

मनुः -

क्लां क्लीं क्लूं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ॥

No. 7289. वेणुश्यामलामन्त्रः.
VĒṆUŚYAMALĀMANTRAḤ.

Pages, 2. Lines, 10 on a page.

Begins on fol. 229*a* of the MS. described under No. 124, wherein it is found in the Sadāmnāyamantra 228*b* given therein in the list of other works.

Complete.

The repetition of this Mantra addressed to Vēṇuśyāmālā, who is conceived as the presiding deity of the flute, is held to have the power to enable one to compose literary works of value.

Beginning:

अस्य श्रीवेणुश्यामलामन्त्रस्य मतङ्गभगवानृषिः, अनुष्टुप् छन्दः, वेणुर्देवता, वेणुश्यामलाप्र—गः ।

End:

ओं नमो भगवते वें वेणवे मम साहित्यविद्यां प्रयच्छ स्वाहा । साहित्यविद्याम्बादिव्यश्रीपादुकां पूजयामि नमः ॥

No. 7290. वेदव्यासगायत्रीमन्त्रः.
VĒDAVYASAGĀYATRĪMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 14*a* of the MS. described under No. 5786, wherein it is wrongly stated as beginning on fol. 14*b* in the list of other works.

Complete.

This is a Gāyatrīmantra as appertaining to Vēdavyāsa; and its repetition is held to secure his favour. For what is meant by Gāyatrī, see under No. 7027.

Beginning :

गुरुनमस्कारः—

ओं पूर्णज्ञानाय विद्महे पूर्णानन्दाय धीमहि ।

तन्नो व्यासः प्रचोदयात् । इति प्राणायामः (१२). पूर्णज्ञानेत्यादिषडङ्गन्यासः ।

* * * *

अस्य श्रीवेदव्यासगायत्रीमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीवेदव्यासो देवता; श्रीवेदव्यासप्रेरणया श्रीवेदव्यासप्रीत्यर्थे जपे विनियोगः ।

End :

ओं पूर्णज्ञानाय विद्महे पूर्णानन्दाय धीमहि । तन्नो व्यासः प्रचोदयात् । इति जपः । उपसंहारः पूर्ववत् ॥

Colophon :

व्यासगायत्री ॥

No. **7291.** वेदव्यासमन्त्रः.

VĒDAVYĀSAMANTRAḤ.

Page, 1. Lines, 18 on a page

Begins on fol. 325*b* of the MS. described under No. 5477, wherein it is found in the Mantramalikā 273*a* in the list of other works given therein.

Complete.

This Mantra is also addressed to Vēdavyāsa.

Beginning :

अस्य श्रीवेदव्यासमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीवेदव्यासो देवता, व्यासायेति षडङ्गन्यासः ।

End :

ओं वेदव्यासाय पूर्णज्ञानाय पूर्णानन्दाय स्वाहा । इति ॥

No. 7292. वेदव्यासाष्टाक्षरमन्त्रः.

VĒDAVYĀSĀṢṬĀKṢARAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 14*a* of the MS. described under No. 5786.

Complete.

Similar to the above. This Mantra consists of eight syllables when the syllable Ōm is left out of account.

Beginning:

गुरुनमस्कारः—

ओं वां वेदव्यासाय नमः इति प्राणायामः १२. पूर्णज्ञानेत्यादि-न्यासः ।

अस्य श्रीवेदव्यासमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्री-वेदव्यासो देवता; श्रीवेदव्यासप्रेरणया वेदव्यासप्रीत्यर्थे जपे विनि-योगः ।

End:

वेदव्यासाष्टाक्षरमहामन्त्रजपं करिष्ये ।

ओं वां वेदव्यासाय नमः — इति जपः । उपसंहारः पूर्ववत् ॥

No. 7293. वेदव्यासैकाक्षरमन्त्रः.

VĒDAVYĀSAIKĀKṢARAMANTRAḤ

Pages, 2. Lines, 8 on a page.

Begins on fol. 14*b* of the MS described under No. 5786, wherein it is wrongly stated as Vēdavyāsanavākṣarī in the list of other works.

Complete.

This Mantra consists of the single syllable व्यां, which is held to denote Vēdavyāsa.

Beginning :

गुरुनमस्कारः —

व्यां इति प्राणायामः (१२). पूर्णज्ञानेत्यादिन्यासः ।

अस्य श्रीएकाक्षरवेदव्यासमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, वेदव्यासो देवता; वेदव्यासप्रेरणया वेदव्यासप्रीत्यर्थे जपे विनियोगः ।

End :

एकाक्षरवेदव्यासमहामन्त्रजपं करिष्ये—ओं व्यां ओं—इति जपः, उपसंहारः पूर्ववत् ॥

No. 7294. व्याधिमन्त्रः.
VYĀDHIMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 44*b* of the MS. described under No. 2886, wherein it is found in the Ākāśabhairavakalpa 38*a* given therein in the list of other works.

Complete.

The name of the work, of which this apparently forms the 37th chapter, seems to be Ākāśabhairavakalpa.

The repetition of this Mantra addressed to Śiva is held to have the power to enable one to make one's enemies suffer from various kinds of diseases

Beginning :

व्याधिमन्त्रस्य वीरभद्र ऋषिः, अनुष्टुप् छन्दः, महाव्याधिकरशिवः, व्यां बीजं, हुं शक्तिः,

विनियोगोऽनिशं भक्ताः शत्रुनाशाय पीडने ।

End :

यत्साध्यं लिखितं व्याधेः तत्तद्व्याधिर्भविष्यति ।

तद्रोगं रिपुराश्रित्य सुभगेऽनुभवेद्ध्रुवम् ॥

Colophon :

इति सप्तत्रिंशोऽध्यायः ॥

No. **7295.** व्याहृतिमन्त्रः.

VYĀHṚTIMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 5*b* of the MS. described under No. 5786.

Complete.

This Mantra consists of the Mahāvyāhṛtis **भूः, भुवः, सुवः,** and their combination, these being generally repeated with the Praṇava. Its repetition is intended to propitiate Viṣṇu.

Beginning:

अथ व्याहृतिमन्त्रः—

ओं भूः ओं भुवः ओं सुवः ओं भूर्भुवस्सुवः इति प्राणायामः १२.

* * * *

अस्य श्रीव्याहृतिमन्त्रस्य प्रजापतिः ऋषिः, गायत्री छन्दः, परमात्मा श्रीहरिर्देवता ; श्रीहरिप्रेरणया श्रीहरिप्रीत्यर्थं जपे विनियोगः ।

End:

यथाशक्ति नियमेन व्याहृतिमन्त्रजपङ्करिष्ये—ओं भूः ओं भुवः ओं सुवः ओं भूर्भुवस्सुवः —इति जपः । उपसंहारः पूर्ववत् ॥

No. 7296. शकटासुरसंहारकगोपालमन्त्रः.

ŚAKAṬĀSURASAṀHĀRAKAGOPĀLAMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 44*b* of the MS. described under No. 5885.

Complete.

This Mantra is addressed to Kṛṣṇa conceived as the cowherd, who, while lying in the cradle playfully, killed with a kick a certain Asura or demon, who, under the orders of Kaṁsa, assumed the form of a cart with a view to crush to death under its wheels the child Kṛṣṇa.

Beginning:

अस्य श्रीशकटासुरसंहारकगोपालमन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, शकटासुरसंहारकगोपालो देवता ; श्रीं बीजं, हुं शक्तिः, फट् कीलकं. शकटासुरसंहारकगोपालप्रीत्यर्थे जपे विपियोगः ।

End:

ओं श्रीं कृष्णाय हुं फट् स्वाहा ॥

No. **7297.** शक्तिगणपतिमन्त्रः.

ŚAKTIGAṆAPATIMANTRAḤ.

Pages, 2. Lines, 12 on a page.

Begins on fol. 19*a*. The other works contained herein and referred to under No 547 are Parabrahmavidyāmantra 1*a*, Kāmakalānyāsa 1*a* and 28*b*. Tripurasundarīmālāmantra 1*b*, Tripurasundarīkavaca 4*a*. Tripurasundaryaṣṭōttaraśata 8*a*, Dēvyupaniṣad Pādukāmantra 13*a*. Gurumantra 13*b*, Mēdhādakṣiṇāmūrtimantra 14*a*, Mēdhādakṣiṇāmūrtikavaca 14*b*. Pañcadaśākṣarīmantra 15*b*, Ṣōḍaśākṣarīmahātripurasundarīmantra 16*a*. Rājarājēśvarīkavaca 16*b*, Bhūtaśuddhi 17*a*. Garuḍapañcākṣarīmantra 19*b*, Bālāparamēśvarīmantra 19*b*, Pañcākṣarīmālāmantra 20*a*. Tripurasundarīmālāmantra 21*a* Śrīvidyāvyākaraṇa 24*a*, Sādhakamaṇḍalīvandana 31*a*, Śrīcakrākṣaravinyāsa 32*a*.

Complete.

This Mantra is addressed to Śaktigaṇapati, i e., to Vināyaka as associated with his wife Vallabhā ; and its repetition is held to have the power to enable one to accomplish one's desires. The syllable Hrīm—ह्रीं—in the Mantra is the mystic symbol denoting Śakti.

Beginning:

अस्य श्रीशक्तिगणपतिमहामन्त्रस्य गणक ऋषिः, नृचिद्गायत्री छन्दः, श्रीशक्तिगणपतिर्देवता. गं बीजं. गीं शक्तिः. गूं कीलकं, सर्वाभीष्टसिद्ध्यर्थे शक्तिगणपतिप्रसादसिद्ध्यर्थं जपे विनियोगः ।

End:

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपते वरवरद सर्वजनं मे वशमानय स्वाहा ॥

No. 7298. शक्तिगणपतिमन्त्रः.

ŚAKTIGAṆAPATIMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 291*a* of the MS. described under No. 5477, wherein it is included in the Mantramālikā 273*a* in the list of other works given therein.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशक्तिगणपतिमन्त्रस्य गणक ऋषिः, निचृद्गायत्री छन्दः, शक्तिगणपतिर्देवता, गं बीजं, ह्रीं शक्तिः, ममेष्टकाम्यार्थसिद्ध्यर्थे जपे विनियोगः ।

End:

ह्रीं ग्लौं महागणपतये नमः, पञ्चलक्षं पुनश्चरणम् ॥

No. 7299. शक्तिगणपतिमन्त्रः.

ŚAKTIGAṆAPATIMANTRAḤ.

Page, 1. Lines, 27 on a page

Begins on fol. 246*b* of the MS described under No. 581, wherein it is found in the Mantramālikā 229*a* given therein in the list of other works

Complete.

Similar to the above

Beginning:

(अस्य श्रीशक्तिगणपतिमन्त्रस्य) गणक ऋषिः, निचृद्गायत्री छन्दः, श्रीशक्तिगणपतिर्देवता, गं बीजं, ह्रीं शक्तिः, ममेष्टकाम्यार्थसिद्ध्यर्थे विनियोगः ।

End:

ह्रीं गौं महागणपतये नमः ।
पञ्चलक्षं जपेन्मन्त्रं पुरश्चरणसिद्धये ॥

No. 7300. शक्तिगणपतिमन्त्रः.

ŚAKTIGAṆAPATIMANTRAḤ.

Pages, 2. Lines, 10 on a page.

Begins on fol. 96*a* of the MS described under No 5566, wherein it has been omitted to be included in the list of other works given therein.

Complete.

Same as the above.

No. 7301. शक्तिन्यासः.

ŚAKTINYĀSAḤ.

Pages, 4. Lines, 10 on a page.

Begins on fol. 191*a* of the MS. described under No. 124.

Complete.

On details connected with the ceremonial touching of certain parts of the body, while repeating at the same time the appropriate Śaktimantras; this kind of Nyāsa is held to be a necessary preliminary to the repetition of the Śrīvidyāmantra.

Beginning:

अथ शक्तिन्यासः —तत्र प्रथमं जगच्छून्याकारं निरालम्बं ध्यात्वा, हुं पृथिव्यै नम इति स्वासनाधः पृथिवीं संपूज्य, स्वासनं वामहस्तेन स्पृशन् भुवनेश्वरीबीजं सप्तवारं जपित्वा, ऐं ह्रीं श्रीं जयायै विजयायै ४ जैत्र्यै ४ अजितायै ४ अपराजितायै सङ्गमायै रम्भायै इति स्वासने सप्तशक्तिं संपूज्य, मूलविद्यया प्राणायामत्रयं कृत्वा, अस्य श्रीमहाशक्तिन्यासस्य परमशिव ऋषिः, अतिजगती छन्दः, श्रीपराशक्तिर्देवता, ऐं बीजं, श्रीं शक्तिः, सौः कीलकं, श्रीविद्याङ्गत्वेन महाशक्तिन्यासे विनियोगः ।

End:

इति सप्तधा संपूज्य, धूपदीपौ नै(नि)वेद्य तस्मिन् त्रैपुरे देहे ऐं ईं सौः इति वनिताक्षोभकरीं महाकामकलां ध्यायेत् ॥

Colophon:

इति शक्तिन्यासविधिः समाप्तः ॥

No. 7302. शक्तिपञ्चाक्षरीमहामन्त्रः.

ŚAKTIPAÑCĀKṢARĪMAHĀMANTRAḤ.

Page, 1 Lines, 5 on a page.

Begins on fol. 51*a* of the MS. described under No. 235.

Complete.

The repetition of this Mantra is intended to propitiate Śiva as associated with Śakti

Beginning:

अस्य श्रीशक्तिपञ्चाक्षरीमहामन्त्रस्य सद्योजात ऋषिः, जगती छन्दः, श्रीशक्तिपञ्चाक्षरी देवता; ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, श्रीशक्तिपञ्चाक्षरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं ह्रीं नमश्शिवाय ॥

No. 7303. शक्तिपञ्चाक्षरीमहामन्त्रः.

ŚAKTIPAÑCĀKṢARĪMAHĀMANTRAḤ.

Pages, 2. Lines, 10 on a page.

Begins on fol. 9*a* of the MS. described under No. 6518.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशक्तिपञ्च(ाक्षरी)महामन्त्रस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः, उमामहेश्वरो देवता; ओं बीजं, ह्रीं शक्तिः, नम इति कीलकं, श्री-उमामहेश्वरप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं ह्रीं हौं नमश्शिवाय, हौं ह्रीं ओं उमामहेश्वराय नमः, श्री-महामायायै नमः, ओं अम्बिकायै नमः, शिवकाम्यै नमः, परमगुरुभ्यो नमः ॥

No. **7304.** शक्तिप्रत्यङ्गिरामालामन्त्रः.

ŚAKTIPRATYAṄGIRĀMĀLĀMANTRAH.

Pages, 11. Lines, 5 on a page.

Begins on fol. 81*a* of the MS. described under No. 29, wherein it is given as Prātyangīramantra in the list of other works

Complete as found in the Rudrayāmala.

This Mantra is addressed to the goddess Śaktipratyaṅgirā, and is considered to be of use in causing the destruction of one's enemies. The authorship of this Mantra is attributed to Śiva.

Beginning:

अस्य श्रीशक्तिप्रत्याङ्गिराउग्रकृत्यादेवीमहामन्त्रस्य प्रत्याङ्गिरा ऋषयः, त्रिष्टुप् छन्दः, श्रीशक्तिप्रत्याङ्गिरा उग्रकृत्या देवता, ह्रीं बीजं, क्रों शक्तिः, श्रीं कीलकं, मम सर्वशत्रुसंहरणार्थे . . . . . श्रीप्रत्यङ्गिरामहादेवीप्रसादसिद्ध्यर्थं प्रत्याङ्गिरामन्त्रजपं करिष्ये ।

End:

ओं ह्रीं ईं ग्लौं श्रीं सौं ऐं हुं नमः कृष्णवाससे शतसहस्रसिंह-वदने अष्टादशभुजे . . . .

ओं सर्वसंहारकारिणि महाप्रत्यङ्गिरे सर्वशात्रवोन्मूलिनि स्वाहा ॥

Colophon:

इति श्रीरुद्रयामले शूलपाणिविरचितायां(तः) शक्तिप्रत्यङ्गिरास्तवराजं-(जः)सम्पूर्णम्(ः) ॥

No. **7305.** शक्तिप्रत्यङ्गिरामालामन्त्रः.

ŚAKTIPRATYAṄGIRĀMĀLĀMANTRAḤ.

Pages, 7. Lines, 5 on a page.

Begins on fol. 93*a* of the MS. described under No. 537.

Complete as found in Rudrayāmala.

Similar to the above.

This manuscript is stated to have been transcribed by Mājēṭi Śarvēśaliṅga.

Beginning :

अस्य श्रीशक्तिप्रत्यङ्गिराउग्रकृत्यादेवीमहामन्त्रस्य प्रत्यङ्गिरा ऋषयः, त्रिष्टुप् छन्दः, श्रीशक्तिप्रत्यङ्गिरा उग्रकृत्या देवी देवता; ह्रीं बीजं, क्रों शक्तिः, श्रीं कीलकं, मम सर्वशत्रुसंहारणार्थे परमन्त्रपरयन्त्रपरकर्मपर-विद्याद्याभिचारिकविच्छेदनार्थे . . . . . प्रत्याङ्गिरामन्त्रजपं करिष्ये ।

End :

शत्रून् सन्तापय सन्तापय हुं फट् स्वाहा । ओं सर्वसंहारका-रिणि महाप्रत्यङ्गिरे सर्वशास्त्र(त्र)वोन्मूलिनि स्वाहा ॥

Colophon :

इति श्रीरुद्रयामले शूलपाणिविरचितायां(तः) शक्तिप्रत्यङ्गिरास्तवराजं-(जः)सम्पूर्णम्(:) ॥

* * * *

भद्रं नो अभिपातु ते नमः । शां ॥

Colophon :

प्रत्यङ्गिरास्तवराजं सम्पूर्णम् ॥

No. 7306. शक्तिमन्त्रः.

ŚAKTIMANTRAḤ

Pages, 2. Lines, 10 on a page.

Begins on fol. 82*b* of the MS. described under No. 21.

Complete.

This Mantra is addressed to the goddess Śakti.

Beginning :

ओन्नमो भगवति सिद्धपरञ्ज्योतिः रुद्राणि सर्वाणि सर्वमङ्गळा सर्वग्रहभयङ्करी महावीरशाक्तिशङ्करवल्लभि ।

End :

रौद्ररणवीरभद्रेश्वरि आं हुं फट् स्वाहा ॥

No. **7307.** **शक्तिमातृकान्यासः.**

ŚAKTIMĀTṚKĀNYĀSAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 193*a* of the MS. described under No 124, wherein it is found in Daśavidhamātṛkānyāsa 192*a* in the list of other works.

Complete.

On the ceremonial touching of certain parts of the body, while repeating the series of Mantra-formulas formed by introducing ह्रीं before and after each of the same six letters of the alphabet.

Beginning:

अथ शक्तिमातृकान्यासः—

अस्य श्रीशक्तिमातृकान्यासस्य वसिष्ठ ऋषिः, सूतश्छन्दः, शक्तिर्देवता, हं बीजं, ईं शक्तिः, ब्रह्मा बीजं, माया शक्तिः, शिवो बीजं, बुद्धिशक्तिः, उदानो बीजं, सुषुम्ना शक्तिः, रेफः कीलकं, श्रीशक्तिमातृकान्यासे विनियोगः ।

End:

ह्रीं अं नमः ह्रीं इत्यादि क्षान्तं न्यसेत् ॥

Colophon:

इति शक्तिमातृकान्यासः ॥

No. **7308.** **शङ्खसुवर्णयक्षिणीमन्त्रः.**

ŚAṄKHASUVARṆAYAKṢIṆĪMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 297*b* of the MS. described under No. 5477, wherein it is found in the Mantramalikā 273*a* in the list of other works given therein.

Complete.

This Mantra is addressed to a certain Yakṣiṇī, who is conceived as wearing a garland of conch shells. It seems that a fire-offering followed by the repetition of this Mantra is understood to have the power to enable a man to become wealthy.

Beginning :

ऋष्यादिकं पूर्ववत् । ओं शङ्खधारिणि शङ्खाभरणि द्रां द्रीं क्लीं ब्लीं श्रीं स्वाहा ।

End :

त्रिकोणं होमकुण्डं दशांशं होमं कल्पप्रकारेण जुहुयात् । इति ॥

No. 7309. शङ्खसुवर्णयक्षिणीमन्त्रः.

ŚAṄKHASUVARṆAYAKṢIṆĪMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 251*b* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* in the list of other works.

Complete.

Similar to the above.

Beginning :

ओं शङ्खधारिणि शङ्खाभरणे द्रां द्रीं क्लीं ब्लें श्रीं स्वाहा ।

End :

षडङ्गं मायाबीजं होमप्रकारेण ध्यानम् । त्रिकोणकुण्डे दशांशहोमं कल्पप्रकारेण जुहुयात् ॥

No. 7310. शङ्खसुवर्णयक्षिणीमन्त्रः.

ŚAṄKHASUVARṆAYAKṢIṆĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 99*a* of the MS. described under No. 5566, wherein it has been omitted to be included in the list of other works given therein.

Complete.

Same as the above.

No. 7311. शत्रुविध्वंसिनीशूलिनीमन्त्रः.

ŚATRUVIDHVAṀSINĪŚŪLINĪMANTRAḤ.

Pages, 2. Lines, 9 on a page.

Begins on fol. 47*a* of the MS. described under No. 21

Complete.

This Mantra is addressed to the goddess Śūlinī, so called because she is conceived as having a Śūla in her hand; and its repetition is held to be efficacious in the destruction of one's enemies and in the accomplishment of one's desires.

Beginning:

अस्य श्रीशत्रुविध्वंसिनीमन्त्रस्य ज्वलत्पावक ऋषिः, शत्रुविध्वंसिनी त्रिशूलिनी देवता, मम शत्रुविनाशनार्थे जपे विनियोगः ।

मूलम् शत्रुविध्वंसिनी रौद्री त्रिशिरा रक्तलोचना ।
अग्निज्वाला रक्तमुखी घोरदंष्ट्री त्रिशूलिनी ॥

End:

इद(मं)स्तवं जपेन्नित्यं विजयं शत्रुनाशनम् ।
सहस्रं त्रिदिनं कृत्वा कार्यसिद्धिर्न संशयः ॥

No. 7312. शत्रुसंहारकगोपालमन्त्रः.

ŚATRUSAṀHĀRAKAGŌPĀLAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 50*a* of the MS. described under No. 5685.

Complete.

The repetition of this Mantra addressed to Kṛṣṇa is considered to have the power to enable one to destroy one's enemies

Beginning:

अस्य श्रीशत्रुसंहारकगोपालमन्त्रस्य नारद ऋषिः, बृहती छन्दः, शत्रुसंहारकगोपालो(देवता), ग्लौं बीजं, क्ष्म्रौं शक्तिः, क्लीं कीलकं, शत्रुसंहारकगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

ओं ग्लौं क्ष्म्रौं क्लीं कृष्णाय ज्वल हुं फट् स्वाहा ॥

No. 7313. शनिकवचम्.
ŚANIKAVACAM.

Pages, 2. Lines, 9 on a page.

Begins on fol. 44b of the MS. described under No. 5945.

Complete; as found in the Skāndapurāṇa.

This Mantra is in praise of the planet Saturn; and its repetition is considered to have the power to remove all kinds of evils and to confer on one prosperity and protection.

Beginning:

शृणुध्वं मुनयस्सर्वे शनिपीडाहरं शुभम् ।
कवचं ग्रहराजस्य शनेरिदमनुत्तमम् ॥
कवचं देवतावासः कवचं वज्रपञ्जरम् ।
सर्वपीडाहरश्श्रीमान् सर्वसौभाग्यदायकः ॥
शिरश्शनैश्चरः पातु फालं वै सूर्यसम्भवः ।
नेत्रे संज्ञासुतः पातु श्रोत्रे पातु यमस्तथा ॥

End:

मृत्युस्थानगतो वापि शुभस्थानगतोऽपि वा ।
एतत्ते कवचं सौरेः कवचं ब्रह्मनिर्मितम् ॥

Colophon:

इति स्कान्दपुराणे प्रभासखण्डेऽवशिष्टापदेशो नाम चत्वारिंशोऽध्यायः ॥

No. 7314. शनैश्चरकवचम्.
ŚANAIŚCARAKAVACAM.

Page, 1. Lines, 19 on a page.

Begins on fol. 51a of the MS described under No. 2886, wherein it is found in the Navagrahakavaca 51a.

Complete as found in the Pādmapurana.

Similar to the above. Held also to be efficacious in effecting the accomplishment of one's desires.

Beginning:

अस्य श्रीशनैश्चरकवचस्तोत्रमहामन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, शनैश्चरो देवता, शनैश्चरप्र—गः ।

*   *   *   *

शनैश्चरः शिरो रक्षेत् मुखं भक्तार्तिनाशनः ।
कर्णौ कृष्णाम्बरः पातु नेत्रे सर्वभयङ्करः ॥

End:

य इदं कवचं दिव्यं सर्वपापहरं नृणाम् ।
पठति श्रद्धया युक्तः सर्वान् कामानवाप्नुयात् ॥

Colophon:

इति पाद्मपुराणे शनैश्चरकवचं सम्पूर्णम् ॥

No. **7315.** शनिद्वादशनामानि.
ŚANIDVĀDAŚANĀMĀNI.

Page, 1. Lines, 19 on a page.

Begins on fol. 190*b* of the MS. described under No. 5673, wherein it is given as Śanaiścaramantra in the list of other works.

Complete.

It is stated that if a person repeats, near an Aśvattha tree, the twelve names of Śani herein given, he will not be troubled by the evil influence of that planet. It is difficult to make out how the first stanza in the extract below contains all the twelve names of Śani.

Beginning and **End:**

कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ।
सौरिश्शनैश्चरो मन्दः पिप्पलादिषु संस्थितः ॥
एतद् द्वादश नामानि जपेदश्वत्थसन्निधौ ।
शनैश्चरकृता पीडा न कदाचिद्भविष्यति ॥

Colophon:

इति शनैश्चरमन्त्रपारायणविधिः ॥

No. 7316. शनैश्चरमन्त्रः.

ŚANAIŚCARAMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 311*b* of the MS. described under No. 5477, wherein it is found in the Mantramālikā 273*a* given in the list of other works.

Complete.

The repetition of this Mantra is considered to have the power to propitiate the planet Saturn.

Beginning:

अस्य श्रीशनैश्चरमन्त्रस्य इरीनम ऋषिः, शनैश्चरो देवता, उष्णिक् छन्दः, मम शनैश्चरप्रसादसिद्ध्यर्थे विनियोगः । श्रामित्यादिषडङ्गन्यासः ।

End:

ओं श्रां श्रीं श्रूं शनैश्चराय नमः । लक्षं जपः । दशांशहोमः ॥

No. 7317. शब्दाकर्षिणीमन्त्रः.

SABDĀKARṢIṆĪMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 45*a* of the MS. described under No. 2886, wherein it is found in the Ākāśabhairavakalpa 38*a*.

Complete.

The repetition of this Mantra is considered to have the power to enable one to hear sounds which otherwise cannot possibly reach one's ears.

Beginning:

शब्दाकर्षिणिकायाः बलप्रमथनः, जगती, शब्दाकर्षिणिका, वं बी, स्वाहा श, शब्दाकर्षणसिद्ध्यर्थे, वामित्यादिन्यासः ।

End:

ततः पश्चात्सर्वमये शब्दानाकर्षयाथ तम् ।
स्वाहेति मन्त्ररूपं तु चत्वारिंशन्महार्णकम् ॥
चत्वारिंशत्सहस्रं जपः ॥

No. 7318. शरणागतिमन्त्रः.
ŚARAṆĀGATIMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 1*a* of the MS. described under No. 5854, wherein it is given as Dvyamantra in the list of other works.

Complete.

This Mantra is addressed to Nārāyaṇa. It is generally known as the Dvayamantra of the Śrīvaiṣṇavas, and inculcates the doctrine that complete self-surrender to God is the easiest means of attaining soul-salvation.

Beginning:

अस्य श्रीशरणागतिद्वयमन्त्रस्य अन्तर्यामी भगवान् श्रीमन्नारायण ऋषिः, देवी गायत्री छन्दः, श्रीविष्णुः परमात्मा नारायणो देवता; ओं बीजं, नमश्शक्तिः, प्राणात्मकाय कीलकं, श्रीमन्नारायणप्रीत्यर्थे जपे विनियोगः ।

End:

श्रीमंन्नारायणचरणौ शरणं प्रपद्ये श्रीमते नारायणाय नमः ॥

Colophon:

इति द्वयमन्त्रः ॥

No. 7319. शरणागतिमन्त्रः.
ŚARAṆĀGATIMANTRAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 11*b* of the MS. described under No. 3546

Complete.

Similar to the above.

Beginning :

अस्य श्रीशरणागतिमहामन्त्रस्य प्रपञ्चशरीरी जीवरूपी विराट् पुरुष ऋषिः, देवी गायत्री छन्दः, परमात्मा देवता, परब्रह्मणः क्षेत्रं, परब्रह्मणः स्वरूपं, श्रीमन्नारायणप्रीत्यर्थे जपे विनियोगः ।

End :

क्षीराम्भोनिधिरत्नमण्टपमहासौवर्णसिंहासने
वामाङ्कस्थितया प्रसन्नवदनं श्रीकान्तयालिङ्गितम् ।
दोर्दण्डाङ्कितशङ्खपङ्कजगदाचक्रैरुदाराश्रियं
त्वामित्थं कलयामि जन्मविमुखो लक्ष्मीशनारायणम् ॥

No. **7320.** शरणागतिमन्त्रः.

ŚARAṆĀGATIMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 4*a* of the MS. described under No. 5915.

Complete.

Similar to the above.

Beginning :

अस्य श्रीशरणागतिमन्त्रस्य अन्तर्यामी भगवान् लक्ष्मीनारायण ऋषिः, श्रीं बीजं, नमश्शक्तिः, श्रीमते (इ) ति कीलकं, श्रीमन्नारायणप्रीत्यर्थे जपे विनियोगः ।

See under the previous number for the end.

No. **7321.** शरभकवचः.

ŚARABHAKAVACAḤ.

Pages, 3. Lines, 19 on a page.

Begins on fol. 38*a* of the MS. described under **No.** 2886, wherein it is found in the Ākāśabhairavakalpa 38*a*.

Complete.

This Mantra is in praise of Śiva who is stated in the Liṅga-purāṇa to have once assumed a peculiar beast-and-bird form and overpowered Nṛsiṁha; and its repetition is considered to have the power to secure protection to one from all dangers.

Beginning :

शिवः—

कथ्यामि शृणु ते देवि सर्वरक्षणमच्युतम् ।
शारभं कवचं नाम चतुर्वर्गफलप्रदम् ॥
शरभसालुवपक्षिराजाख्यकवचस्य तु ।
सदाशिव ऋषिश्छन्दो बृहती परमेश्वरः ॥
देवता प्रणवं बीजं प्रकृतिः शक्तिरुच्यते ।
कीलकं पक्षिराजः स्यात् सर्वरक्षाकरो विभुः ॥

* * *

श्रीशिवः पुरतः पातु मायाधीशस्तु पृष्ठतः ।
पिनाकी दक्षिणं पातु वामपार्श्वे महेश्वरः ॥

End :

यत्कृत्यं तन्न कृतं यदकृत्यं कृत्यवत्तदाचरितम् ।
उभयोः प्रायश्चित्तं शिव तव नामाक्षरद्वयोच्चरितम् ॥

Colophon :

इत्याकाशभैरवकल्पे शरभकवचस्तोत्रं नाम चत्वारिंशोऽध्यायः ॥

No. 7322. शरभकवचः.

ŚARABHAKAVACAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol 12*b* of the MS. described under No. 2886.

Complete.

Similar to the above.

Beginning :

श्रीशिवः पुरतः पातु मायाधीशस्तु पृष्ठतः ।
पिनाकी दक्षिणं पातु वामपार्श्वे महेश्वरः ॥

जिह्वाग्रं पातु शम्भुश्च निटिलं शङ्करस्तथा ।
ईश्वरो वदनं पातु भ्रुवोर्मध्यं पुरान्तकः ॥

End:

इति गुह्यं महामन्त्रं परमं सर्वसिद्धिदम् ।
शरभेशाख्यकवचं चतुर्वर्गफलप्रदम् ॥

No. 7323. शरभकवचः.

ŚARABHAKAVACAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 157*a* of the MS. described under No. 5661.

Incomplete.

Similar to the above. Also held to be efficacious in the accomplishment of the four Puruṣārthas or principal aims of life.

Beginning:

देवादिदेवस्सर्वज्ञः सर्वभूतहिते रत ।
केन रक्षा भवेन्नृणां भीतिनां विविधापरे ॥
राजचोरादिपीडासु शस्त्राग्नीनां भयेषु च ।
मारीदुस्स्वप्नपीडासु ग्रहपीडानिवारणे ॥

* * * *

सालुवः पक्षिराजस्य कवचस्य सदाशिवः ।
ऋषिश्छन्दोऽस्य बृहती देवता शरभेश्वरः ॥

* * * *

अस्य श्रीशरभकवचस्तोत्रमहामन्त्रस्य सदाशिव ऋषिः, बृहती छन्दः, श्रीशरभेश्वरो देवता; ओं बीजं, प्रकृतिश्शक्तिः, पक्षिराजेति कीलकं, मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।

End:

श्रीशिवः पुरतः पातु मायाधीशस्तु पृष्ठतः ।

No. **7324.** **शरभकवचः.**

ŚARABHAKAVACAḤ.

Pages, 23. Lines, 5 on a page.

Begins on fol. *29a* of the MS. described under No. 5660.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशरभकवचस्तोत्रमन्त्रस्य सदाशिव ऋषिः, बृहती छन्दः, शरभेश्वरो देवता, ओं बीजं, ह्रीं शक्तिः, पक्षिनाथः, कीलकं, मम शरभेश्वरप्रसादसिद्ध्यर्थे जपे विनियोगः ।

* * * *

ओं शिवः पुरतः पातु मायाधीशस्तु पृष्ठतः ।
पिनाकी दक्षिणं पातु (वामपार्श्वे तु) शङ्करः ॥

End:

देवदेव महादेव शिवनाम दयानिधे ।
पाहि मां प्रणतस्वामिन् प्रसीद सततं मम ॥

Colophon:

इति शरभसाल्व(कवच)स्तोत्रं सम्पूर्णम् ॥

No. **7325.** **शरभकालीमन्त्रः.**

ŚARABHAKĀLĪMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. *12a* of the MS. described under No. 5864.

Complete.

This Mantra is addressed to the goddess Śarabha Kālī; and its repetition is considered to have the power to enable one to counteract the hostile movements of one's enemies.

Beginning:

अस्य श्रीशरभकालीमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, शरभकाली देवता, ग्लौं बीजं, ह्रीं शक्तिः, हुं कीलकं, मम श्रीशरभकालीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

खें खड्गेन आशु छेदय खे खे रक्तं पिब शीघ्रं क्रिमिमान् खादय हुं फट् स्वाहा ॥

Colophon:

शरभकाळी (मन्त्रः) समाप्तः ॥

No. 7326. शरभचित्कलाकर्षणमालामन्त्रः.

ŚARABHACITKALĀKARṢAṆAMALĀMANTRAḤ.

Pages, 6. Lines, 5 on a page.

Begins on fol. 110*a* of the MS. described under No. 29, wherein it is given as Śarabhakalākarṣaṇamālikā in the lst of other works.

Complete.

This Mantra which is addressed to Śiva is considered to have the power to enable one to deprive a person of his intelligence with a view to gain complete mastery over him and thus accomplish one's desires.

Beginning:

अस्य श्रीचित्कलाकर्षणमालामन्त्रस्य वामदेवभगवानृषिः, जगती छन्दः, श्रीवीरशरभेश्वरो देवता, खें बीजं, ह्रीं शक्तिः, फट् कीलकं, मम विनियोगः ।

End:

शार्दूलचर्मवसनाय शरभसाल्वाय सूर्यसोमाग्निलोचनाय दुर्निवारणाय दूर्वादलश्यामलाय दुरितहरणाय ओं श्रीं फें आकर्षय ॥

No. 7327. शरभचित्कलाकर्षणमालामन्त्रः.

ŚARABHACITKALĀKARṢAṆAMĀLĀMANTRAḤ

Pages, 4. Lines, 6 on a page.

Begins on fol. 192*b* of the MS. described under No. 537.

Complete.

Similar to the above. Seems to have also the power of preventing evils that may be caused by evil spirits and hostile Mantras.

Beginning:

अस्य श्री(शरभ)चित्कलाकर्षणमालामन्त्रस्य वामदेवभगवानृषिः, जगती छन्दः, श्रीवीरशरभेश्वरो देवता; खें बीजं, ह्रीं शक्तिः, फट् कीलकं, मम विनियोगः ।

End:

मम किङ्करीभूतं कुरु कुरु खं खं खं खें खें खें ह्रीं श्रीं वीरशरभाय फट् फट् स्वाहा ॥

सिद्धमन्त्रमिदं ख्यातं न जपैर्न च होरुभिः ।
एकोच्चारणभक्तेन सर्वं सिध्यति तत्क्षणात् ॥

* * * *

देवदत्तस्य मन्त्रदेवताबन्धनं स्यात् । ब्रह्मराक्षसानां बन्धनं स्यात् । सर्वेषां विधिरेषा ॥

No 7328. शरभचित्कलामन्त्रः.

ŚARABHACITKALĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 28*a* of the MS. described under No. 5737, wherein it has been omitted to be included in the list of other works.

Complete.

The repetition of this Mantra is intended to propitiate Śiva.

Beginning:

अस्य श्रीशरभचित्कलामन्त्रस्य वामदेव ऋषिः, जगती छन्दः, शरभेश्वरो देवता, खं बीजं, स्वाहा शक्तिः; फट् कीलकं, मम शरभेश्वरप्रसादासिद्ध्यर्थे जपे विनियोगः ।

End:

ह्रीं श्रीं वीरशरभ हुं फट् स्वाहा ॥

अष्टाङ्घ्रिश्च सहस्रबाहुरनलच्छायाशिरोयुग्मभृद्-
द्विर्त्र्यक्षिर्द्विहृदच्छपुच्छमुदितस्साक्षान्नृसिंहाजि(र्द)नः ।
अर्धेनापि मृगाकृतिः पुनरथो ह्यर्धेन पक्ष्याकृतिः
श्रीवीरश्शरभस्स पातु रु(मु)चिराद्विद्यात्सदा मां हृदि ॥

No. 7329. शरभादिग्बन्धनमन्त्रः.

ŚARABHADIGBANDHANAMANTRAḤ

Page, 1. Lines, 19 on a page.

Begins on fol. 39*b* of the MS. described under No. 2886, wherein it is found in the Ākāśabhairavakalpa 38*a*.

The repetition of this Mantra which is addressed to Śiva is considered to have the power to safeguard one from the dangers coming from the various quarters and also to drive off evil spirits.

Beginning:

शरभदिग्बन्धनमन्त्रस्य वामदेव ऋषिः, अतिजगती छन्दः, शरभः, खां बीजं, स्वाहा शक्तिः, क्रौं कीलकं, शरभदिग्बन्धने विनियोगः ।

End:

ओं दक्षध्वंसशरभाय सर्वद्वारं बन्ध २ मां रक्ष २ महायोगेश्वर भूतप्रेतपिशाचानुच्चाटयोच्चाटय महाशरभसालुवपक्षिराजाय हुं फट् स्वाहा ॥

Colophon:

इति दिग्बन्धः ॥

No. 7330. शरभमालामन्त्रः.

ŚARABHAMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 195*a* of the MS. described under No. 537.

Complete.

The repetition of this Mantra is intended to propitiate Śarabhēśvara who is the same as Śiva.

Beginning:

अस्य श्रीअघोरशरभमालामन्त्रराजमहामन्त्रस्य अघोरेश्वर ऋषिः, गायत्री छन्दः, श्रीशरभेश्वरो देवता; खं बीजं, फं शक्तिः, आं कीलकं, श्रीशरभेश्वरप्रीत्यर्थे जपे विनियोगः ।

End:

रुन्धय रुन्धय त्रोटय त्रोटय क्रोशय क्रोशय क्रुद्धय क्रुद्धय रोधय रोधय घातय घातय श्रीं ह्रीं अन्धय अन्धय ओं ॥

No. **7331.** शरभमालामन्त्रः.

ŚARABHAMĀLĀMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 46*b* of the MS. described under No 5660, wherein it is wrongly mentioned to begin on fol. 46*a*.

Complete.

Similar to the above.

Beginning:

मालामन्त्रः—

ओं नमोऽष्टपादाय सहस्रबाहवे द्विशिरस्त्रिनेत्राय द्विपक्षायाग्निवर्णाय ।

End:

आपदुद्धारणशरभसाल्वपक्षिराजाय हुं फट् स्वाहा ॥

No. **7332.** शरभसालुवद्वात्रिंशदक्षरमन्त्रः.

ŚARABHASĀLUVADVĀTRIMŚADAKṢARAMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol 191*a* of the MS. described under No. 537.

Complete.

This Mantra, consisting of 32 syllables, is addressed to Śiva. Its repetition is considered to have the power to enable one to destroy one's enemies.

Beginning:

अस्य श्रीशरभसालुवमन्त्रस्य वामदेव ऋषिः, जगती छन्दः, शरभसालुवपक्षिराजपरमात्मा देवता; खें बीजं, स्वाहा शक्तिः, ग्रं कीलकं, मम शरभसालुवप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं खें खें घं ग्रं सिं हुं फट् । सर्वशत्रुसंहरणाय शरभसालुवपक्षिराजाय हुं फट् स्वाहा ॥

No. **7333.** शरभसालुवद्वात्रिंशदक्षरमन्त्रः.

ŚARABHASĀLUVADVĀTRIṀŚADAKṢARAMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 105*a* of the MS. described under No. 29, wherein it is given as Śarabhasāluvamantra in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशरभसाल्वमन्त्रस्य वामदेव ऋषिः, जगती छन्दः, श्रीशरभसाल्वपक्षिराजपरमात्मा देवता; खें बीजं, स्वाहा शक्तिः, ग्रं कीलकं, मम शरभसाल्वप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

सर्वशत्रुसंहरणाय शरभसाल्वपक्षिराजाय हुं फट् स्वाहा ॥

No. **7334.** शरभसाल्वपक्षिराजकवचः.

ŚARABHASĀLVAPAKṢIRĀJAKAVACAḤ.

Pages, 4. Lines, 36 on a page.

Begins on fol. 78*a* of the MS. described under No. 1493, wherein it has been omitted to be included in the list of other works contained therein.

Complete as found in the Ākāśabhairavakalpa.

Similar to the work described under No. 7321.

Held to be efficacious in counteracting the hostile movements of unfriendly people and in effecting the accomplishment of one's desires.

Beginning :

अस्य श्रीशरभसाल्वपक्षिराजकवचराजमहामन्त्रस्य सदाशिव ऋषिः, बृहती छन्दः, श्रीशरभेश्वरो देवता; खें बीजं, स्वाहा शक्तिः, हुं कीलकं, परप्रयोगशान्तिद्वारा मम सर्वाभीष्टसिद्ध्यर्थे शरभसाल्वपक्षिराजजपे विनियोगः ।

* * * *

श्रीशिवः पुरतः पातु मायाधीशस्तु पृष्ठतः ।
पिनाकी दक्षिणं पातु वामपार्श्वे महेश्वरः ॥

End :

देवदेव महादेव शिव कारुण्यवारिधे ।
देहि मे ह्यचलां भक्तिं प्रसीद मम सत्तमा ॥

Colophon :

इति श्रीमदाकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे श्रीशङ्करेण विरचिते शरभसाल्वपक्षिराजाख्यकवचं नाम चतुश्चत्वारिंशोऽध्यायः ॥

No. **7335.** शरभसालुवपक्षिराजकवचः.

ŚARABHASĀLUVAPAKṢIRĀJAKAVACAḤ.

Pages, 22. Lines, 5 on a page.

Begins on fol. 3*b* of the MS. described under No. 5122.

Complete.

Same as the above.

No. **7336.** शरभसालुवपक्षिराजकवचः.

ŚARABHASĀLUVAPAKṢIRĀJAKAVACAḤ.

Pages, 15. Lines, 5 on a page.

Begins on fol. 158*a* of the MS. described under No. 5661.

Complete as found in the 36th Adhyāya of the Ākāśabhairavakalpa.

Similar to the above.

Beginning :

अस्य श्रीशरभसाल्वपक्षिराजकवचस्तोत्रमन्त्रस्य सदाशिववामदेवा ऋषयः, बृहती अनुष्टुप् छन्दांसि, श्रीशरभसाल्वेश्वरो देवता, ओं बीजं,

ह्रीं शक्तिः, श्रीशरभेश्वरः कीलकं, मम सकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

* * * *

श्रीशिवः पुरतः पातु मायाधीशस्तु पृष्ठतः ।
पिनाकी दक्षिणं पातु वामपार्श्वे महेश्वरः ॥

End:

देवदेव महादेव शिव कारुण्यवारिधे ।
पाहि मां प्रणतस्वामिन् प्रसीद सततं मम ॥

Colophon:

इति श्रीआकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शरभसाल्वपक्षिराजकवचं नाम षट्त्रिंशोऽध्यायः ॥

No 7337. शरभसालुवपक्षिराजदिग्बन्धनमन्त्रः.
ŚARABHASĀLUVAPAKṢIRĀJADIGBANDHANA-MANTRAḤ.

Pages, 4. Lines, 5 on a page.

Begins on fol. 47*a* of the MS. described under No. 5660, wherein it has been omitted to be included in the list of other works given therein.

Complete.

Similar to the Mantra described under No. 7329.

Beginning:

ओं नमः पक्षिराजाय निशितकुल(लिश)परा(नखा)य देहकोटिब्रह्म-कपाल . . . शरभसाल्वाय पक्षिराजाय ह्रां ह्रीं ह्रूं प्रवेशय प्रवेशय बन्धय बन्धय ।

End:

नाशय नाशय नाशय सर्वदुष्टान् नाशय हुं फट् स्वाहा ॥

Colophon:

इति दिग्बन्धनम् ॥

No. 7338. शरभसाल्वपक्षिराजमहामन्त्रः.

ŚARABHASĀLVAPAKṢIRĀJAMAHĀMANTRAḤ.

Pages, 5. Lines, 5 on a page.

Begins on fol. 49*a* of the MS. described under No. 5660, wherein it is given as Śarabhasālvamantra.

Complete.

This Mantra is addressed to Śiva, who is said in the Liṅga-purāṇa to have assumed a peculiar beast-and-bird form and vanquished Nṛsiṁha; its repetition is considered to be efficacious in causing the destruction of one's enemies.

Beginning:

अस्य श्रीशरभसाल्वपक्षिराजमहामन्त्रस्य वामदेव ऋषिः, अतिजगती छन्दः, शरभसाल्वपक्षिराज[illegible] कालाग्निरुद्रो देवता, खं बीजं, स्वाहा शक्तिः, कूं कीलकं मम सर्वशत्रुसंहारणार्थे जपे विनियोगः ।

End:

मनुः--

खें खें खां खं फट् प्राणग्रहासि प्राणग्रहासि हुं फट् सर्वशत्रुसंहारणाय शरभसाल्वपक्षिराजाय हुं फट् स्वाहा ॥

No. 7339. शरभसालुवपक्षिराजमालामन्त्रः.

ŚARABHASĀLUVAPAKṢIRĀJAMĀLĀMANTRAḤ

Pages, 2. Lines, 6 on a page

Begins on fol. 194*a* of the MS. described under No. 7247.

Complete.

This Mantra is in praise of Śiva under various significant names. It is held to be efficacious in causing the destruction of one's enemies.

Beginning:

ओं नमः पक्षिराजाय निशितकुलिशवरनखायानेककोटिब्रह्मकपालमालालङ्कृताय सकलकुलमहानागभूषणाय सर्वभूतनिवारणाय नरसिंहगर्वनिर्वापणाय सकलारिपुरम्भाटवीमोटननिलयाय शरभसालुवाय ।

End:

वद वदाज्ञापयाज्ञापय हुं हुं हुं ग्लौं ग्लौं ग्लौं ढं ढं ढं फट् फट् ॥

No. **7340.** शरभसालुवपक्षिराजमालामन्त्रः.

ŚARABHASĀLUVAPAKṢIRĀJAMĀLĀMANTRAḤ.

Pages, 5. Lines, 5 on a page.

Begins on fol. 107*b* of the MS. described under No. 29, wherein it has been omitted to be included in the list of other works.

Complete.

Similar to the above.

For the beginning, see under the previous number.

End:

रुन्धय रुन्धय त्रोटय त्रोटय क्रोशय क्रोशय कुड्डय कुड्डय रोधय रोधय घातय घातय श्रीं ह्रीं . अन्धय अन्धय ओं प्रीयतां

No. **7341.** शरभसालुवपक्षिराजमालामन्त्रः.

ŚARABHASĀLUVAPAKṢIRĀJAMĀLĀMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 40*a* of the MS. described under No. 2886.

Complete.

Similar to the above

The object aimed at by the repetition of this Mantra is the destruction of bad people.

Beginning:

श्रीशिवः—

ओं नमः पक्षिराजाय निशितकुलिशवरनखाय अनेकब्रह्मकपालमालालङ्कृताय सकलकुलमहानागभूषणाय सर्वभूतनिवारणाय नरसिंहगर्वनिर्वापणकारणाय ।

End:

मुञ्च मुञ्च दह दह पच पच नाशय नाशय सर्वदुष्टान् नाशय हुं फट् स्वाहा ॥

No. **7342.** शरभसालुवपक्षिराजमालामन्त्रः.

ŚARABHASĀLUVAPAKṢIRĀJAMĀLĀMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 42*a* of the MS. described under No. 2424.

Complete.

Same as the above.

No. **7343.** शरभसालुवपक्षिराजमालामन्त्रः.

ŚARABHASĀLUVAPAKṢIRĀJAMĀLĀMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 107*a* of the MS. described under No. 235, wherein it is found in the Mahāvidyā 90*a* in the list of other works.

Complete.

Similar to the above. Held also to be efficacious in removing all kinds of evils.

Beginning:

ओं नमो भगवते पक्षिराजाय निशितकुलिशवरनखाय अनेककोटिब्रह्माण्डमालालङ्कृतशरीराय सकलनागकुलमहाविभूषणाय सकलशत्रुनिवारणाय सर्वभूतनिवारणाय नृसिंहगर्वनिर्वापणाय सकलरिपुहाटक[टि]मोटनाय शरभसाल्वाय ।

End:

प्रलयकालवीरभद्राय खें खें हुं महाकारवीरभद्राय दुरितवि(निवारणाय) ओं फट् स्वाहा ॥

No. **7344.** शरभसालुवपक्षिराजमालामन्त्रः.

ŚARABHASĀLUVAPAKṢIRĀJAMĀLĀMANTRAḤ.

Pages, 1. Lines, 17 on a page.

Begins on fol. 85*b* of the MS. described under No 5586, wherein it is found in the Mahāvidyā 65*b*.

Complete.

Same as the above.

No. **7345.** शरभसालुवमन्त्रः.

ŚARABHASĀLUVAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 151*a* of the MS. described under No. 5661, wherein it is wrongly given as Śarabhasālvakavaca in the list of other works.

Complete.

Similar to the work described under No. 7338.

Held also to have the power to enable one to obstruct the bodily and intellectual powers of bad people and to accomplish one's objects.

Beginning:

अस्य श्रीशरभसाल्वमहामन्त्रस्य कालाग्निरुद्र ऋषिः, जगती छन्दः, श्रीशरभसाल्वेश्वरो देवता, खें वीजं, स्वाहा शक्तिः, श्रीशरभसाल्वप्रसादसिद्ध्यर्थे मम दूरस्थानां समीपस्थानां सर्वदुष्टानां वाक्पदगातिमतिजिह्वामुखस्तम्भनार्थे . . . .
मम इष्टकाम्यार्थसिद्ध्यर्थे श्रीशरभसाल्वमहामन्त्रजपे विनियोगः ।

End:

शरभेश्वर विश्वेश पक्षिराज दयानिधे ।
देहि मेऽचञ्चलां भक्तिं प्रणतोऽस्मि पुनः पुनः ॥

मानसपञ्चपूजा । लं पृथिव्यात्मने शरभसाल्वाय गन्धं समर्पयामि । . . . . वं अमृतात्मने शरभसाल्वाय अमृतोपहारनैवेद्यं समर्पयामि ॥

No. 7346. शरभसालुवमन्त्रः.

ŚARABHASĀLUVAMANTRAḤ.

Pages, 2. Lines, 27 on a page.

Begins on fol. 23?b of the MS. described under No. 581, wherein it is found in the Mantramālikā 229a given therein in the list of other works.

Complete.

Similar to the above. Held to be efficacious in causing the destruction of one's enemies and the accomplishment of one's desires.

Beginning:

अस्य श्रीशरभसालुवमन्त्रस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः, महाप्रलयकालरुद्रो देवता, खें वीजं, स्वाहा शक्तिः, सर्वशत्रुसंहारिणीति कीलकं, ममेष्टार्थे सर्वशत्रुक्षयार्थे विनियोगः ।

End:

सर्वशत्रुसंहारिणे शरभसालुवाय पक्षिराजाय हुं फट् ॥

No. **7347.** शरभसालुवमन्त्रः.

ŚARABHASĀLUVAMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 91*b* of the MS. described under No. 5566, wherein it is wrongly stated to begin on fol. 93.

Complete.

Same as the above.

No. **7348.** शरभसालुवमन्त्रः.

ŚARABHASĀLUVAMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 281*b* of the MS. described under No. 5477, wherein it is found in the Mantramālikā 273*a* given therein in the list of other works.

Complete.

Similar to the above

The aim of this Mantra is to enable one to drive away one's enemies.

Beginning:

अस्य श्रीशरभसालुवमन्त्रस्य वामदेव ऋषिः, अनुष्टुप् छन्दः, श्रीशरभसालुवरुद्रो देवता, खें बीजं, स्वाहा शक्तिः, सर्वशत्रुसंहारणेति कीलकं, मम शत्रुपलायनार्थे विनियोगः ।

End:

ओं खें खें फं प्रसो प्रसि हुं फट् श्रीशरभसालुवाय पक्षिराजाय

No. **7349.** शरभसालुवमन्त्रः.

ŚARABHASĀLUVAMANTRAḤ.

Pages, 2 Lines, 6 on a page.

Begins on fol. 27*a* of the MS. described under No. 5737.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशरभसालुवमहामन्त्रस्य कालाग्निरुद्र ऋषिः, अतिजगती छन्दः, शरभसालुवपक्षिराजकालाग्निरुद्रो देवता; खं बीजं, स्वाहा शक्तिः, फट् कीलकं, मम शरभसालुवप्रीत्यर्थे जपे विनियोगः ।

End:

सकलरिपुदम्भाटवीमोटनमहानलाय शरभसाल्वाय पक्षिराजाय ह्रां ह्रीं हूं प्रवेशय प्रवेशय भाषय भाषय मोहय मोहय स्वाहा ॥

No. **7350.** शरभसालुवमन्त्रराजमहामन्त्रः.

ŚARABHASĀLUVAMANTRARĀJAMAHĀMANTRAḤ.

Pages, 2. Lines, 9 on a page.

Begins on fol. 191*a* of the MS. described under No. 7247

Complete.

This Mantra is considered to be the most important of the Mantras addressed to Śiva conceived as Śarabhasāluva. It is considered to be of help in the accomplishment of the four Puruṣārthas, viz., Dharma. Artha Kāma and Mōkṣa.

Beginning:

अस्य श्रीशरभसालुवमन्त्रराजमहामन्त्रस्य कालाग्निरुद्र ऋषिः, जगती छन्दः, श्रीशरभेश्वरो देवता; खं बीजं, स्वाहा शक्तिः, फट् कीलकं, मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ।

End:

अथ मनुः—

ओं खें खां खं फट् प्राणग्रहाशि प्राणग्रहाशि हुं फट् । सर्वशत्रुसंहारणाय शरभसालुवपक्षिराजाय हुं फट् स्वाहा । पुनः प्राणानायम्य न्यासध्यानादिकं कृत्वा अनेन मया कृतेन प्रीयतां न मम ॥

No **7351.** शरभसालुवमन्त्रराजमहामन्त्रः.

ŚARABHASĀLUVAMANTRARĀJAMAHĀMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 105*a* of the MS. described under No. **29**, wherein it is found in Śarabhasaluvamantra 105*a*

Complete.

Similar to the above.

Beginning :

अस्य श्रीशरभसालुवमन्त्रराजमहामन्त्रस्य कालाग्निरुद्र ऋषिः, जगती छन्दः, श्रीशरभेश्वरो देवता; खं बीजं, स्वाहा शक्तिः, फट् कीलकं मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ।

End :

ओं खें खां खं फट् प्राणग्रहाशि प्राणग्रहाशि हुं फट् । सर्वशत्रुसंहरणाय शरभसाल्वाय पक्षिराजाय हुं फट् स्वाहा । पुनः प्राणानायम्य, न्यासध्यानादिकं कृत्वानेन मया कृतेन प्रीयतां न मम ॥

No. **7352.** शरभसालुवमन्त्रराजमहामन्त्रः.

ŚARABHASĀLUVAMANTRARĀJAMAHĀMANTRAḤ.

Pages. 2. Lines, 6 on a page.

Begins on fol. 191*b* of the MS. described under No. 7247.

Complete.

Similar to the above.

Beginning :

अस्य श्रीशरभसालुवमन्त्रराजमहामन्त्रस्य दूर्वासभगवानृषिः, अनुष्टुप् छन्दः, श्रीशरभेश्वरो देवता; ह्रीं बीजं, क्लीं शक्तिः, सौः कीलकं, मम विनियोगः ।

End :

ओं श्रीं ह्रीं अग्निनेत्रज्वालामालाय श्रीनृसिंहविदारणशरभेश्वराय क्लीं सौं ह्रां ह्रीं स्वाहा । पुनः प्राणायामः । न्यासध्यानादिकं विधाय अनेन मया प्रीयतां ममः ॥

No. **7353.** शरभसालुवमन्त्रराजमहामन्त्रः.

ŚARABHASĀLUVAMANTRARĀJAMAHĀMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 104*a* of the MS. described under No. 29, wherein it is found in Śarabhasāluvamantra 105*a*.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशरभसालुवमन्त्रराजमहामन्त्रस्य दूर्वासभगवानृषिः, अनुष्टुप् छन्दः, श्रीशरभेश्वरो देवता ; ह्रीं बीजं, क्लीं शक्तिः, सौः कीलकं, मम जपे विनियोगः ।

End:

ओं श्रीं ह्रीं अग्निनेत्रज्वालामालाय श्रीनृसिंहविदारणशरभेश्वराय क्लीं सौः ह्रूं ह्रीं स्वाहा । पुनः प्राणायामन्यासध्यानादिकं विधाय अनेन मया (कृतेन प्रीयतां न मम) ।

No. 7354. शरभसालुवमालामन्त्रः.

ŚARABHASĀLUVAMĀLĀMANTRAḤ

Pages, 2 Lines, 5 on a page

Begins on fol. 109*b* of the MS. described under No. 29, wherein it is given as Śarabhāṣṭōttara-śatanyāsa in the list of other works.

Complete.

Similar to the above.

The supplicant prays to Śiva in the end to bestow immortality on him

Beginning:

अस्य श्रीशरभसालुवमालामन्त्रस्य [राज]भगवान् सदाशिव ऋषिः, जगती छन्दः, श्रीशरभेश्वरो देवता; शं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, मम विनियोगः ।

End:

कालकण्ठाय गरलसंहारणाय भूर्भुवस्सुवःपतये मृत्युपतये अमृतं मे प्रयच्छ स्वाहा । पुनर्ध्यात्वानेन प्रीयतां न मम ॥

No. 7355. शरभसालुवमालामन्त्रः.

ŚARABHASĀLUVAMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 192*a* of the MS. described under No. 537

Complete.

Same as the above.

Beginning:

अस्य श्रीशरभसालुवमालामन्त्रस्य भगवान् सदाशिव ऋषिः, जगती छन्दः, श्रीशरभेश्वरो देवता ; शं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, मम विनियोगः ।

End:

मृत्युपतये अमृतं मे प्रयच्छ स्वाहा । शां शं ह्रीं ओं । पुनर्ध्यात्वा अनेन प्रीयतां नं मम ॥

No **7356.** शरभसाल्वमन्त्रः.

ŚARABHASĀLVAMANTRAḤ.

Page, 1. Lines, 4 on a page.

Begins on fol. 25*b* of the MS. described under No. 5600, wherein it has been apparently omitted to be included in the list of other works.

Complete.

Similar to the work described under No. 7345.

Beginning:

अस्य श्रीसाल्वशरभमन्त्रस्य वामदेव ऋषिः, अतिजगती छन्दः, साल्वपक्षिराजकालाग्निरुद्रो देवता ; खं बीजं, स्वाहा शक्तिः, सर्वशत्रुसंहारेति कीलकं, मम साल्व—गः ।

End:

ओं खें खां खं फट् प्राणग्रहासि प्राणग्रहासि हुं फट् । सर्वशत्रुसंहारिणे शरभसाल्वाय पक्षिराजाय हुं फट् स्वाहा ।

ओं सालुवाय विद्महे पक्षिराजाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥

No. **7357.** शरभसाल्वमन्त्रः.

ŚARABHASĀLVAMANTRAḤ

Pages, 2. Lines, 5 on a page.

Begins on fol. 31*a* of the MS. described under No. 5422

Complete.

Similar to the above.

Beginning :

अस्य श्रीशरभसाल्वमन्त्रराजमहामन्त्रस्य वामदेव ऋषिः, अनुष्टुप् छन्दः, श्रीशरभसाल्वेश्वरो देवता, ओं बीजं, ग्रिं शक्तिः, फट् कीलकं, श्रीशरभसाल्वप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

खें खें खं फं ग्रं शुं हुं फट् फट् सर्वशत्रुसंहारणाय शरभसाल्वाय पक्षिराजाय हुं फट् स्वाहा ॥

Colophon :

सम्पूर्णश्शरभसाल्वमन्त्रः ॥

No. 7358. शरभसाल्वमन्त्रः.

ŚARABHASĀLVAMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 4*a* of the MS. described under No. 7261.

Complete.

Same as the above.

No. 7359. शरभसाल्वमन्त्रः.

ŚARABHASĀLVAMANTRAḤ.

Pages, 4. Lines, 6 on a page.

Begins on fol. 33*a* of the MS. described under No. 3862.

Complete.

Similar to the above.

Beginning :

अस्य श्रीशरभसाल्वमहामन्त्रस्य वामदेव ऋषिः, अतिजगती छन्दः, श्रीशरभेश्वरो देवता, ओं बीजं, स्वाहा शक्तिः, ह्रीं कीलकं, मम शरभसाल्वेश्वरप्रसादसिद्ध्यर्थं जपे विनियोगः ।

End:

चन्द्रार्कौ यस्य दृष्टिः कुलिशवरनखश्चञ्चलात्युग्रजिह्वः
काली दुर्गा च पक्षौ हृदयजठरगौ भैरवो वाडवाग्निः ।
ऊरुस्थौ व्याधिमृत्यू चलदनलशिखश्चवातादिवेसः(ण्डवातातिवेगः)
संहर्ता सर्वशत्रून् स जयतु शरभस्सालुवः पक्षिराजः ॥
मनुः ॥

No. **7360.** शरभसाल्वमन्त्रः.

ŚARABHASĀLVAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 1*a* of the MS. described under No. 5686.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशरभसाल्वमन्त्रस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः, श्रीशरभसाल्ववीरभद्रो देवता; ओं बीजं, स्वाहा शक्तिः, खें कीलकं, श्रीशरभसाल्वप्रीत्यर्थे जपे विनियोगः ।

End:

ओं खें घं फं भीं शिं शुं हुं फट् फट् सर्वशत्रुसंहारणाय शरभसाल्वपक्षिराजाय हुं फट् स्वाहा ॥

No. **7361.** शरभसाल्वमन्त्रः.

ŚARABHASĀLVAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 149*b* of the MS. described under No. 781.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशरभसाल्वमन्त्रस्य वामदेव ऋषिः, अनुष्टुप् छन्दः, शरभेश्वरो देवता; श्रीं बीजं, ध्रं शक्तिः, फट् कीलकं, श्रीशरभसाल्वप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं खें खं फं ध्रं शुं हुं फट् सर्वशत्रुसंहारणाय शरभसाल्वाय पक्षिराजाय हुं फट् स्वाहा ॥

No. 7362. शरभसाल्वमन्त्रः.
ŚARABHASĀLVAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 113*a* of the MS. described under No. 119.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशरभसाल्वमन्त्रस्य वामदेव ऋषिः, जगती छन्दः, शरभसाल्वकालाग्निरुद्रो देवता; खें बीजं, स्वाहा शक्तिः, श्रीशरभसाल्वप्रीत्यर्थे विनियोगः ।

End:

हुं फट् सर्वशत्रुसंहाराय शरभसाल्वाय पक्षिराजाय हुं फट् स्वाहा ।
पुरश्चरणमयुतम् ॥

No. 7363. शरभसाल्वमन्त्रराजमहामन्त्रः.
ŚARABHASĀLVAMANTRARĀJAMAHĀMANTRAḤ

Pages, 4. Lines, 4 on a page.

Begins on fol. 21*a* of the MS described under No. 5828, wherein it is given as Śarabhasāluvamantra in the list of other works.

Incomplete.

Similar to the work described under No. 7353.

Intended to propitiate Śiva as associated with Pārvatī.

Beginning:

अस्य श्रीशरभसाल्वमन्त्रराजमहामन्त्रस्य कालाग्निरुद्र ऋषिः, अतिजगती छन्दः, श्रीशरभसाल्वकालाग्निरुद्रो देवता, खं बीजं, स्वाहा शक्तिः, फं कीलकं, पार्वतीसमेतश्रीशरभसाल्वप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

शत्रुसंहारिणे अस्त्राय फट्, भूर्भुवस्सुवरोमिति दिग्ब.

No. **7364.** **शरभसाल्वमालामन्त्रः.**

ŚARABHASĀLVAMĀLĀMANTRAḤ.

Pages, 5. Lines, 5 on a page.

Begins on fol. 166*a* of the MS. described under No. 5661, wherein it is given as Śarabhamālāmantra in the list of other works.

Complete.

This Mantra is in praise of Śiva and is considered to have the power to bring people under one's control and influence and to destroy one's enemies, etc.

Beginning:

ईश्वर उवाच—

ओन्नमः पक्षिराजाय निशितकुलिशवरनखाय अनेककोटिब्रह्मकपाल-मालालङ्कृताय सकलकुलमहानागभूषणाय.

End:

सर्वलोकवशङ्करि सर्वजनं मे वशमानय स्वाहा । ओं खें खें फट् प्राणग्रहासि प्राणग्रहासि हुं फट् सर्वशत्रुसंहरणाय शरभसाल्वाय पक्षि-राजाय हुं फट् स्वाहा ॥

No. **7365.** **शरभसाल्वमालामन्त्रः.**

ŚARABHASĀLVAMĀLĀMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 53*b* of the MS. described under No. 5660, wherein it is found in the Śarabhasāluvamantra 49*a*.

Complete.

Similar to the above.

Beginning:

ओं नमो महावीरघोरशरभाय खं खं खं खं फं फं फं फं ठ ठ ठ ठ ग्रं सौं ग्रं सिं हुं हुं वीरप्रचण्डपक्षिराजशरभसाल्वाय ।

End:

खें खें वं ग्रां सौं सिं हुं हुं वीरप्रचण्डपक्षिराजशरभसाल्वाय हुं फट् स्वाहा ॥

No. 7366. शरभसाल्वेश्वरमन्त्रः.

ŚARABHASĀLVĒŚVARAMANTRAḤ.

Pages, 4. Lines, 18 on a page.

Begins on fol. 50*b* of the MS described under No. 5673, wherein it is found in the Āmnāyamantramālikā 1*a*.

Complete.

Similar to the Mantra described under No. 7356.

Beginning :

अस्य श्रीशरभसाल्वेश्वरमहामन्त्रस्य वामदेव ऋषिः, अतिजगती छन्दः, श्रीशरभसाल्वेश्वरो देवता ; खें बीजं, स्वाहा शक्तिः, फ्रें कीलकं, मम श्रीशरभसाल्वेश्वरप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

चन्द्रार्कौ वह्नि(यस्य)दृष्टी कुलिशवरनखाश्चञ्चलात्युग्रजिह्वाः
काली दुर्गा च पक्षौ हृदयजठरगौ भैरवो बाडबाग्निः ।
ऊरुस्थौ व्याधिमृत्यू शरभवरखगश्चण्डवातातिवेगः
संहर्ता सर्वशत्रून् जयतु स शरभस्सालुवः पक्षिराजः ॥

No. 7367. शरभेश्वरमन्त्रः.

ŚARABHĒŚVARAMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 40*a* of the MS. described under No. 2836, wherein it is found in the Ākāśabhairavakalpa 38*a*.

Complete.

Similar to the above.

Beginning :

श्रीशरभेश्वरमहामन्त्रस्य कालाग्निरुद्र ऋषिः, जगती छन्दः, श्रीशरभेश्वरो देवता ; खं बीजं, स्वाहा शक्तिः, ओं खें खां अं। खं फट् त ।

End :

ओं खें खां फट् खं प्राणग्रहासि प्राणग्रहासि हुं फट् । सर्वशत्रुसंहारणाय शरभसालुवाय पक्षिराजाय हुं फट् स्वाहा—इति मनुः ॥

ध्यानान्तरम्—

अष्टाङ्घ्रिश्च सहस्रबाहुर(म)लच्छायाशिरोयुग्मभृत्
द्वित्र्यक्षोऽतिजवो द्विपक्ष उदितस्संक्षोभिसिंहासहः ।
अर्धेनापि मृगाकृतिः पुनरथाप्यर्धेन पक्ष्याकृतिः
श्रीवीरः शरभस्स पातु सुचिरं नीत्वा सदा मां हृदि ॥

क्षीरोदनेन होमः ॥

No 7368. शरीरशुद्धिमन्त्रः.

ŚARĪRAŚUDDHIMANTRAḤ.

Pages, 3. Lines, 7 on a page.

Begins on fol. 1*a* of the MS. described under No. 5786.

Complete.

The repetition of this Mantra is considered to have the power to enable one to purify one's self from sin.

Beginning:

जपकर्ता विविक्तदेशमागत्य प्रणवेन जलमभिमन्त्र्य तज्जलेन जपस्थानं संप्रोक्ष्य ऐन्द्रादिदिक्षु बध्नामि * * मम शरीरशुद्धिमन्त्रस्य अन्तर्यामी ऋषिः, प्रकृतिपुरुषश्छन्दः, सत्यो देवता, समस्तभूतोच्चाटने विनियोगः ।

End:

श्रीवासुदेवो भगवान्मच्छरीरमाज्ञादृष्ट्या वरुणेनाप्लावयतु, मां पवित्रीकरोतु ॥

No. 7369. शरीरशुद्धिमन्त्रः.

ŚARĪRAŚUDDHIMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 124*a* of the MS. described under No. 119.

Complete.

Similar to the above.

Beginning :

अस्य शरीरशुद्धिमन्त्रस्य आन्त(र)ऋषिः, प्रकृतिश्छन्दः, सद्यो देवता, मम शरीरपाश्चभौतिकशुद्ध्यर्थे विनियोगः ।

End :

सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ।
तत्संयोगपदद्वन्द्वमङ्गप्रत्यङ्गकारकम् ॥

Colophon :

उपपातकरोगपूर्णशरीरशुद्धिमन्त्रं सम्पूर्णम् ॥

No. **7370.** शाम्भवविद्या.

ŚĀMBHAVAVIDYĀ.

Pages, 5. Lines, 27 on a page.

Begins on fol. 64*a* of the MS. described under No. 446.

Complete.

This Mantra is addressed to Śāmbhavī who is Śiva's Śakti conceived as a goddess.

Beginning :

तत्रादौ ब्रह्मरन्ध्रे त्रिकोणं सञ्चिन्त्य तन्मध्ये बिन्दौ श्रीनिर्वाण-शाम्भवं ध्यायेत् । अथ मन्त्रः—

ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं हसक्षमलवरयूं श्रीनवात्मानन्दनाथ ऐं क्ल्रीं श्रीं किणि किणि विच्चे ह्स्फ्रें श्रीनिष्कलामहासमयाम्बापरापराम्बाश्री-पादुकां पूजयामि नमः ।

End :

त्रिशूलवज्रचक्राणि अङ्कुशं शरकर्तरी ।
दक्षिणेनाधुना देवि नीलोत्पलसतारको ॥
अन्यत्र मुण्डखट्वाङ्गं घण्टापुस्तं धनुस्तथा ।
कापालं वामके प्रोक्तं सिंहासनशवासने ॥
इति ध्यात्वा निवेदयेत् ॥

Colophon :

इति शाम्भवप्रकरणम् ॥

No. **7371.** शारिकामन्त्रः.

ŚĀRIKĀMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 13*a* of the MS. described under No. 5673, wherein it is found in the Mantramālikā 1*a* in the list of other works.

· Complete.

This Mantra is addressed to the goddess Śārikā, who is a manifestation of Śyāmalā or Mātaṅgī; and its repetition is held to be efficacious in bringing to one wisdom and enlightenment.

Beginning:

अस्य श्रीशारिकामन्त्रस्य शौनक ऋषिः, अतिजगती छन्दः, श्रीशारिका देवता; ओं बीजं, स्वाहा शक्तिः, नमो भगवतीति कीलकं, मम श्रीशारिकाम्बाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—

ओं नमो भगवति शारिके सकलकलाकोविदे ऐं मम बोधय बोधय स्वाहा । श्रीशारिकाम्बाश्री ॥

No. **7372.** शारिकामन्त्रः.

ŚĀRIKĀMANTRAḤ.

Page, 1. Lines, 4 on a page.

Begins on fol. 28*b* of the MS. described under No 2848, wherein it is found in the Āmnāyamantramālikā 16*a*

For Pūrvāmnāyamantramālikā 16*a* given therein in the list of other works read Āmnāyamantramālikā 16*a*.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशारिकामन्त्रस्य शौनक ऋषिः, पङ्क्तिश्छन्दः, शारिका देवता, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, विनियोगः, श्रीमित्यादिन्यासः ।

End:

ओं ऐं नमो भगवति शारिके सकलकलाकोविदे देवीं बोधय बोधय स्वाहा ॥

No. 7373. शारिकामन्त्रः.
ŚĀRIKĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 3*b* of the MS. described under No. 673, wherein it is found in the Ṣaḍāmnāya 1*a* given therein in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशारिकामन्त्रस्य मतङ्ग ऋषिः, जगती छन्दः, शारिका देवता ; क्लीं बीजं, ह्रीं शक्तिः, सौः कीलकं, मम(देवीं) शारिकाप्रसाद-सिद्ध्यर्थे जपे विनियोगः ।

End:

ओं नमो भगवति शारिके सकलकलाकोविदे देवीं बोधय बोधय स्वहा । शारिकाम्बाश्रीपा—नमः ॥

No. 7374. शारिकाश्यामलामन्त्रः.
ŚĀRIKĀŚYĀMALĀMANTRAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 229*a* of the MS. described under No. 124, wherein it is found in the Ṣaḍāmnāyamantra 228*b* given therein in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशारिकाश्यामलामन्त्रस्य शौनक ऋषिः, अतिजगती छन्दः, शारिका देवता, श्रीशारिकाप्रसाद—गः ।

श्रीमिति करहृदयादिन्यासः ।

End:

देवीं बोधय बोधय स्वाहा । शारिकाम्बादिव्यश्रीपादुकां पूजयामि ।

No. **7375.** शास्तामन्त्रः.
ŚĀSTĀMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 48*b* of the MS. described under No. 2856.

Complete.

This Mantra is addressed to Śāstā who is a village deity generally known as Ayyanār in Tamil ; and its repetition is considered to have the power to bring even celestial beings under one's control and influence.

Beginning:

ह्रीं हरिहरपुत्राय शत्रुनाशनाय मतङ्गजवाहनाय ह्रीं

End:

सुरासुरवशीकरणं कुरु कुरु स्वाहा ॥

No. **7376.** शास्तामन्त्रः.
ŚĀSTAMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 45*a* of the MS. described under No. 2886, wherein it is found in the Ākāśabhairavakalpa 38*a* given therein in the list of other works.

Complete.

Similar to the above.

Beginning:

महाशास्तुः अर्धनारीश्वरः, अनुष्टुप् छन्दः, महाशास्ता हरिहरात्मकः, मायावर्णं बीजं, रमा शक्तिः, सर्वार्थसिद्ध्यर्थे, मूलेन न्यासः ।

End:

मदगजाय च तत्पश्चाद्वाहनायपदं ततः ।
महाशास्ताय तत्पश्चात् नमोऽन्तं मन्त्रमुत्तमम् ॥
त्रयस्त्रिंशद्वर्णः, वर्णसहस्रं जपः । सर्वं पूर्ववत् ॥
बीजं विना त्रिंशदर्णात्परं साध्यं नियोज्य तत् ।
सपल्लवसहस्रं तु जपेत्तता(त्का)म्यसिद्धये ॥

No. 7377. शिंशुमारमन्त्रः.
ŚIṀŚUMĀRAMANTRAḤ.

Page, 1. Lines, 7 on a page.

Begins on fol. 30*b* of the MS. described under No. 5786.

Complete.

This Mantra is addressed to a constellation of very brilliant stars resembling a porpoise situated in the heavens just above the Dhruva or polar star. This celestial porpoise-shaped constellation is conceived to be the same as Nārāyaṇa, the God who is the life and support of all beings.

Beginning:

ओन्नमो भगवते ज्योतिर्लोकाय कालायनाय निमेषपतये महापुरुषाय धीमहीति प्राणायामः । . . . .

अस्य श्रीशिंशुमारमहामन्त्रस्य ब्रह्मा ऋषिः, त्रिष्टुप् छन्दः; शिंशुमारो देवता, शिंशुमारप्रेरणया शिंशुमारप्रीत्यर्थे जपे विनियोगः ।

End:

ओन्नमो भगवते ज्योतिर्लोकाय कालायनाय निमेषपतये महापुरुषाय धीमहि—इति जपः । उपसंहारः पूर्ववत् ॥

No. 7378. शिवकवचः.
ŚIVAKAVACAḤ.

Pages, 17. Lines, 6 on a page.

Begins on fol. 27*a* of the MS. described under No. 408.

Complete.

This Mantra is addressed to Śiva; and its repetition is considered to have the power to secure for one his favour and protection.

Beginning:

अस्य श्रीशिवकवचस्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः, पङ्क्तिश्छन्दः, श्रीसाम्बसदाशिवो देवता; ओं नम इति बीजं, उमेति शक्तिः,

ब्रह्मेति कीलकं, मम साम्बसदाशिवप्रीत्यर्थे शिवकवचमन्त्रपारायणे जपे विनियोगः ।

* * * *

सर्वत्र मां रक्षतु विश्वमूर्तिर्ज्योतिर्मयानन्दघनश्चिदात्मा ।
अणोरणीयानुरुशक्तिरेकस्स ईश्वरः पातु भयादशेषात् ॥

End:

इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां संपूजितस्सोऽथ योगी स्वैरगतिर्ययौ ॥

No. **7379.** शिवकवचः.

ŚIVAKAVACAḤ.

Pages, 13. Lines, 4 on a page.

Begins on fol. 76*a* of the MS. described under No. 132.

Complete as found in the 34th Adhyāya of the Brahmōttara-khaṇḍa forming part of the Skāndapurāṇa.

Similar to the above. Held also to have the power to remove sins and to secure the grace of Śiva.

Beginning:

अस्य श्रीशिवकवचस्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः, अनुष्टुप् छन्दः, सदाशिवो देवता; ओं बीजं, नं शक्तिः, मं कीलकं, मम समस्तपापक्षयद्वारा सदाशिवप्रीत्यर्थे विनियोगः ।

End:

इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां संपूजितस्सोऽथ योगी स्वैरगतिर्ययौ ॥

Colophon:

इति स्कान्दपुराणे ब्रह्मोत्तरखण्डे ऋषभभद्रायुस्संवादे शिवकवचकथनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥

No. 7380. शिवकवचः.
ŚIVAKAVACAḤ.

Pages, 20. Lines, 4 on a page.

Begins on fol. 1*a* of the MS. described under No. 6192.

Complete as found in the 12th Adhyāya of the Brahmōttara-khaṇḍa.

Same as the above with the difference in the colophon which is given below :—

Colophon :

इति श्रीब्रह्मोत्तरखण्डे श्रीब्रह्मनारदसंवादे शिवकवचकथनं नाम द्वादशोऽध्यायः ॥

No. 7381. शिवकवचः.
ŚIVAKAVACAḤ.

Substance, palm-leaf. Size, $10\frac{7}{8} \times 1\frac{1}{3}$ inches. Pages, 14. Lines, 10 on a page. Character, Telugu. Condition, good. Appearance, new.

Complete.

Same as the above with the difference in the colophon as given below :—

Colophon :

इति श्रीब्रह्मोत्तरखण्डे ब्रह्मनारदसंवादे शिवकवचवर्णने द्वादशोऽध्यायः ॥

No. 7382. शिवकवचः.
ŚIVAKAVACAḤ.

Pages, 8. Lines, 8 on a page.

Begins on fol. 13*b* of the MS. described under No. 2902.

Complete.

Same as the above, but without the portion relating to the Ṛṣi, Chandas and Dēvata and with the difference in the colophon as given below :—

Colophon :

इति श्रीस्कन्दपुराणे ब्रह्मोत्तरखण्डे शिवकवचं समाप्तम् ॥

No. 7383. शिवकवचः.

ŚIVAKAVACAḤ.

Pages, 8. Lines, 9 on a page.

Begins on fol. 21*a* of the MS. described under No. 120.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशिवकवचस्तोत्रमहामन्त्रस्य नारायण ऋषिः, अनुष्टुप् छन्दः, श्रीसदाशिवो देवता, ओं बीजं, नमं (नं) शक्तिः, मं कीलकं, श्रीसदाशिवप्रीत्यर्थे जपे विनियोगः ।

See under the next number for the end.

Colophon:

इति स्कान्दे ब्रह्मोत्तरखण्डे ऋषभभद्रायुस्संवादे शिवकवचानुवर्णनं नाम द्वादशोऽध्यायः ॥

No. 7384. शिवकवचः.

ŚIVAKAVACAḤ

Pages, 3. Lines, 8 on a page.

Begins on fol. 130*b* of the MS. described under No. 119.

Complete as found in the Kālikākhaṇḍa of the Skānda Purāṇa.

Similar to the above.

Beginning:

देवानां देवमीशानमादिमध्यान्तवर्जितम् ।
भावगम्यं नमस्कृत्य पप्रच्छ वृषवाहनम् ।

* * * *

ईशो मे पुरतः पातु ईश्वरः पातु पृष्ठतः ।
ईशानः शिरसः पातु मुखे तत्पुरुषस्तथा ॥

End:

इन्द्राग्नियमयक्षेशजलेशवसतीः क्रमात् ।
धनदेशादिपर्यन्तं लोकपालैश्च पालितः ॥

Colophon:

इत्यादिपुराणे स्कान्दे कालिकाखण्डे शिवकवचस्तोत्रं सम्पूर्णम् ॥

No. **7385.** **शिवकवचः.**

ŚIVAKAVACAḤ.

Pages, 14. Lines, 6 on a page.

Begins on fol. 47*a* of the MS. described under No. 408.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशिवकवचस्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः, महाविराट् छन्दः, श्रीसाम्बसदाशिवो देवता; ह्रां बीजं, (ह्रीं) शक्तिः, ह्रूं कीलकं, श्रीसाम्बसदाशिवप्रीत्यर्थे शिवकवचपारायणे विनियोगः।

* * * *

पूर्वतः पातु मामीशः आग्नेय्यां त्रिपुरान्तकः।
दक्षिणे कालविध्वंसी नैरृत्ये सर्पभूषणः॥

End:

क्रूरान्नाशय नाशय मां रक्ष रक्ष अभयं कुरु कुरु हुं फट् स्वाहा॥
नववारमष्टोत्तरशतं वापि यो जपति मन्त्रं (स) निर्भयो भवतीत्याह भगवान् सदाशिवः॥

No **7386.** **शिवकवचः.**

ŚIVAKAVACAḤ.

Pages, 7. Lines, 8 on a page.

Begins on fol. 131*b* of the MS. described under No. 119.

Complete as found in the Brahmōttarakhaṇḍa.

Similar to the above.

Beginning:

अथापरं सर्वपुराणगुह्यमशेषपापौघहरं पवित्रम्।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवं कवचं हिताय वै॥

अस्य श्रीरुद्रब्रह्मविद्यामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, रुद्रो देवता; ह्रां बीजं, ह्रीं शक्तिः, ह्रं कीलकं, मम समस्तदुरितक्षयद्वारा श्रीसाम्बशिवप्रीत्यर्थे जपे विनियोगः।

For the end, see under No. 7379.

Colophon :

इति श्रीब्रह्मोत्तरखण्डे शिवकवचं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥

No. 7387. शिवकवचः.
ŚIVAKAVACAḤ.

Pages, 6. Lines, 5 on a page.

Begins on fol. 25*a* of the MS. described under No. 5422.

Complete.

Similar to the above.

Beginning :

अथापरं सर्वपुराणगुह्यं . . . . हिताय वै ॥
नमस्कृत्वा महादेवं विश्वव्यापिनमीश्वरम् ।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥

End:

शिवकवचेन मामाच्छादयाच्छादय त्र्यम्बक नमस्ते नमस्ते ॥

No. 7388. शिवकवचः.
ŚIVAKAVACAḤ.

Pages, 4. Lines, 5 on a page.

Begins on fol 43*a* of the MS. described under No. 5422.

Complete.

Same as the above.

No. 7389. शिवकवचः.
ŚIVAKAVACAḤ.

Pages, 11. Lines, 5 on a page.

Begins on fol. 16*a* of the MS. described under No. 764.

Complete.

Similar to the above.

Considered to be efficacious in bringing about the accomplishment of one's desires.

Beginning:

अस्य श्रीशिवकवचस्तोत्रमहामन्त्रस्य वामदेव ऋषिः, ह्रीं ओं बीजं नं शक्तिः, मं कीलकं, मम सर्वाभीष्टसिद्ध्यर्थे शिवकवचपारायणे विनियोगः ।

End:

क्षुत्तृष्णातुरं मामाप्याययाप्यायय रुजातुरं मामानन्दयानन्दय शिवकवचेन मामाच्छादयाच्छादय त्र्यम्बक नमस्ते नमस्ते नमः ॥

No. **7390.** शिवकवचः.

ŚIVAKAVACAḤ.

Pages, 2. Lines, 9 on a page.

Begins on fol. 247*b* of the MS. described under No. 124, wherein it is given as Śivakavacastōtra in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशिवकवस्तोत्रमन्त्रस्य ऋषभयोगीश्वर ऋषिः, अनुष्टुप् छन्दः, श्रीसाम्बसदाशिवो देवता, ह्रां बीजं; ह्रीं शक्तिः, ह्रूं कीलकं, मम साम्बसदाशिवप्रसादसिद्ध्यर्थे शिवकवचपारायणे विनियोगः ।

See under the next number for the end.

No. **7391.** शिवकवचः.

ŚIVAKAVACAḤ.

Pages, 5. Lines, 6 on a page.

Begins on fol. 75*a* of the MS. described under No. 5452.

Complete

Similar to the above. This is considered to be the most important of the Mantras in praise of Śiva and Parvati.

Beginning:

भवतीं शरणं गत्वा कृतार्थाः स्युः पुरातनाः ।
इति सञ्चिन्त्य सञ्चिन्त्य देवि त्वां शरणं व्रजे ॥

*   *   *   *

शिवशीतकरार्धाङ्कमणिमौलिविराजितम् ।
शिवाख्यं कवचं तस्मान्मम वक्तव्यमञ्जसा ॥

*   *   *   *

अस्य कवचस्य परब्रह्म ऋषिः, अनुष्टुप् छन्दः, श्रीसदाशिवो देवता, श्रीसाम्बसदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः ।

*   *   *   *

ईशो मे पुरतः पातु ईश्वरः पातु पृष्ठतः ।
ईशानः शिरसि पातु मुखे तत्पुरुषस्तथा ॥

End :

य इदं पठते भक्त्या न साध्यं तस्य विद्यते ।
स्तवानां राजराजोऽयं तस्मात्त्वं जप सर्वदा ॥

Colophon :

इति माधवीये शिवस्तोत्रे रत्नाकरे दिव्यागमे शिवखण्डे शिवेन प्रोक्तं शिवकवचं सम्पूर्णम् ॥

No. 7392. शिवकवचब्रह्मविद्यामन्त्रः.

ŚIVAKAVACABRAHMAVIDYĀMANTRAḤ.

Pages, 3. Lines, 19 on a page.

Begins on fol. 14*a* of the MS. described under No. 2886, wherein it has been apparently wrongly given as beginning on fol. 14*b*.

Complete.

Similar to the above. Also considered to have the power to enable one to obtain a vision of Śiva.

Beginning :

अस्य श्रीशिवकवचब्रह्मविद्यामहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरुद्रो देवता; रां बीजं, रीं शक्तिः, रूं कीलकं, रुद्रसाक्षात्कारसिद्ध्यर्थे जपे विनियोगः । . . . .

मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥
सर्वत्र मां रक्षतु विश्वमूर्तिः ज्योतिर्मयानन्दघनश्चिदात्मा ।
अणोरणीयानुरुशक्तिरेकस्स ईश्वरः पातु भयादशेषात् ॥

End :

त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥

No. **7393.** शिवपञ्चाक्षरीमन्त्रः.

ŚIVAPAÑCĀKṢARĪMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 49*b* of the MS. described under No. 235.

Complete.

This is the well-known five-syllabled prayer-formula of the Śaivas. Its repetition is considered to have the power to propitiate Śiva and to enable one to accomplish one's desires.

Beginning :

मूलेनाचम्य मूलेन प्राणायामं कुर्यात् । अस्य श्रीशिवपञ्चाक्षरीमहामन्त्रस्य वामदेव ऋषिः, अनुष्टुप् छन्दः, श्रीसाम्बसदाशिवो देवता; ओं बीजं, नमः शक्तिः, शिवायेति कीलकं, मम साम्बसदाशिवप्रसादसिद्ध्यर्थे मम सकलमनोरथसिद्ध्यर्थे जपे विनियोगः ।

End :

ओन्नमः शिवाय । जपान्ते पुनराचमनप्राणायामषडङ्गध्यानपञ्चपूजां कुर्यात् ।

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्महेश्वर ॥

अनेन मया कृतं साम्बसदाशिवार्पणमस्तु ॥

No. 7394. शिवपञ्चाक्षरीमन्त्रः.
ŚIVAPAÑCĀKṢARĪMANTRAḤ.

Pages, 2. Lines, 4 on a page.

Begins on fol. 38*a* of the MS. described under No. 6414.

Complete.

Similar to the above.

Beginning :

अस्य श्रीशिवपञ्चाक्षरीमन्त्रस्य ब्रह्मा ऋषिः, दैवी गायत्री छन्दः, सदाशिवो देवता, ओं रं ब्रह्मात्मक इति बीजं, सर्वशक्तिधाम्ने कामिति शक्तिः, त्रिपुरहरण इति कीलकं, मम सर्वाभीष्टफलसिद्ध्यर्थे विनियोगः ।

End :

नमः शिवाय नमः ॥

No. 7395. शिवपञ्चाक्षरीमन्त्रः.
ŚIVAPAÑCĀKṢARĪMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 26*a* of the MS. described under No. 5786.

Complete.

Similar to the above.

The order of the words forming the Mantra-formula is given in this manuscript in a somewhat altered form.

Beginning :

ओं शिवाय नमः ओं इति प्राणायामः । १२.

* * * *

अस्य श्रीशिवपञ्चाक्षरमहामन्त्रस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः, श्रीशिवो देवता, श्रीशिवप्रेरणया शिवप्रीत्यर्थे शिवपञ्चाक्षरमन्त्रजपे विनियोगः ।

End :

ओं शिवाय नमः ओं इति जपः । उपसंहारः पूर्ववत् ॥

No. 7396. शीतलाम्बामन्त्रः.
ŚĪTALĀMBĀMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 1*a* of the MS. described under No. 5832

Complete.

Similar to the above.

Held to be also helpful in counteracting the evils likely to be caused by evil spirits owing to the sin committed by one in a former birth.

Beginning:

अस्य श्रीशीतलाम्बामहामन्त्रस्य आनन्दभैरव ऋषिः, अनुष्टुप्-छन्दः, शीतलाम्बा देवता, ओं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, मम जन्मान्तरप्रतिबन्धकवशात् संप्राप्तनानाग्रहोपघातादिसकलदेवताग्रहनिग्रहादि-सकलपीडानिवृत्त्यर्थं शीतलाप्रसादसिद्ध्यर्थे जपे विनियोगः।

End:

ह्रीं शान्तादेवी च धीमहि। श्रीं शीतलादेवि प्रचोदयात्॥ गुडोदकतर्पणं होमः. . . . . . . श्रीगन्धवारिणा तर्पणं दशांशं, सहस्रं जपः॥

No. 7397. शीतलास्तोत्रमन्त्रः.
ŚĪTALĀSTŌTRAMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 3*a* of the MS. described under No. 2886.

Complete.

This Mantra is addressed to the goddess Śītalā, and is considered to be of use in the curing of small pox and other like epidemics.

Beginning:

स्कन्द उवाच—

भगवन् देवदेवेश शीतलायाः स्तवं शुभम्।
वक्तुमर्हस्यशेषेण विस्फोटकभयापहम्॥

ईश्वर उवाच—

अस्य श्रीशीतलास्तोत्रमहामन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, शीतला देवी देवता, ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, स्फोटकादि-समस्तरोगशान्त्यर्थे जपे विनियोगः ।

End:

आं ह्रीं ओं नमो भगवति शीतले देवि मम स्फोटकं नाशय नाशय तन्त्रं छेदय छेदय दाहं शमय शमय स्वास्थ्यं कुरु कुरु शीतले स्वाहा ॥

Colophon:

शीतलास्तोत्रं सम्पूर्णम् ॥

No. **7398.** शीतलास्तोत्रमन्त्रः.

ŚĪTALĀSTŌTRAMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 65*a* of the MS. described under No. 5661.
Complete, as found in the Skāndapurāṇa.
Similar to the above.

Beginning:

अस्य श्रीशीतलादेवीस्तोत्रमन्त्रस्य शिव ऋषिः, अनुष्टुप् छन्दः, श्रीशीतला देवी देवता; ऐं बीजं, ह्रीं शक्तिः, स्वाहेति कीलकं, श्री-शीतलादेवीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं ह्रीं शीतले स्फोटकान् विनाशय विनाशय निदाघं शमय शमय तन्त्रून् छेदय छेदय ओं शीतले ह्रीं स्वाहा ॥

Colophon:

इति स्कान्दपुराणे ईश्वरप्रोक्तं शीतलास्तोत्रं सम्पूर्णम् ॥

No. 7399. शुकश्यामलामन्त्रः.
ŚUKAŚYĀMALĀMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 12*b* of the MS. described under No. 5673, wherein it is found in the Āmnāyamantramālikā given therein in the list of other works.

Complete.

This Mantra is addressed to Śukaśyāmalā who is the same as the goddess Śyāmalā or Mātaṅgī; and its repetition is considered to have the power to enable one to bring under one's control and influence all people including even kings.

Beginning:

अस्य श्रीशुकश्यामलामहामन्त्रस्य शुकभगवा(ना)नन्दभैरव ऋषिः, पङ्क्तिगायत्री छन्दः, श्रीशुकश्यामला देवता, ओं बीजं, स्वाहा शक्तिः, नमो भगवतीति कीलकं, मम सकलजनवश्यार्थे श्रीशुकश्यामलाप्रसाद-सिद्ध्यर्थे जपे विनियोगः ।

End:

ओं नमो भगवते महाशुकाय त्रैलोक्यमोहनाय त्रिभुवनालङ्का-राय राजमदमर्दनाय शीघ्रं राजानं मे वशमानय स्वाहा। श्रीशुकश्या-मलाश्री ॥

No. 7400. शुकश्यामलामन्त्रः.
ŚUKAŚYĀMALĀMANTRAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 229*a* of the MS. described under No. 124, wherein it is found in the Ṣaḍāmnāyamantra 228*b* given therein in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशुकश्यामलामन्त्रस्य शुक ऋषिः, पङ्क्तिश्छन्दः, शुको देवता, शुकश्यामलाप्रसाद—गः । श्रामिति करहृदयादिन्यासः ।

End:

शीघ्रं राजानं मे वशमानय स्वाहा । शुकश्यामलाम्बादिव्यश्रीपादुकां पूजयामि ॥

No. **7401.** शुकश्यामलामन्त्रः.

ŚUKAŚYĀMALĀMANTRAḤ.

Pages, 2. Lines, 4 on a page.

Begins on fol. 28*a* of the MS. described under No. 2848, wherein it is found in the Āmnāyamantramālikā 1*a* given therein in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशुकमन्त्रस्य शुक ऋषिः, पङ्क्तिश्छन्दः, शुकश्यामलाम्बा देवता, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, विनियोगः; श्रामित्यादिन्यासः ।

End:

शीघ्रं राजानं मे वशमानय स्वाहा । शुकदेव्यम्बाश्री ॥

No. **7402.** शुकश्यामलामन्त्रः.

ŚUKAŚYĀMALĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 3*b* of the MS. described under No. 673, wherein it is found in the Ṣaḍāmnāya 1*a* in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशुकश्यामलामहामन्त्रस्य शुक ऋषिः, पङ्क्तिश्छन्दः, शुकश्यामला देवता; क्लीं बीजं, ह्रीं शक्तिः, सौः कीलकं, मम शुकश्यामलाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं नमो भगवते महाशुक्राय त्रिभुवनालङ्कृताय राजमदमर्दनाय श्रेष्ठं राजानं मे वशमानय स्वाहा । शुक्रश्यामलाश्री—नमः ॥

No. **7403.** शुक्रकवचम्.

ŚUKRAKAVACAM.

Page, 1. Lines, **19** on a page.

Begins on fol. 51*a* of the MS. described under No. 2886, wherein it is found in the Navagrahakavaca 51*a*.

Complete as found in the Skāndapurāṇa.

This Kavacamantra is addressed to Śukra, who, according to the Purāṇas, was the priest and preceptor of the Asuras; and its repetition is considered to have the power to secure protection to one from all troubles and dangers.

Beginning:

मृणालकुन्देन्दुपयोहिमप्रभं श्वेताम्बरं स्निग्धसिताक्षमालिनम् ।
समस्तशास्त्रश्रुतितत्त्वदर्शिनं ध्यायेत्कविं वाञ्छितवस्तुलब्धये ॥
शिरो मे भार्गवः पातु फालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु कर्णौ श्रीकण्ठभक्तिमान् ॥

End:

य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥

Colophon:

इति स्कान्दे पुराणे शङ्करसंहितायां शुक्रकवचं सम्पूर्णम् ॥

No. **7404.** शुक्रमन्त्रः.

ŚUKRAMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 311*a* of the MS. described under No. 5477, wherein it is found in the Mantramālikā 273*a* in the list of other works.

Complete.

This **Mantra** is intended to propitiate Śukra the priest and preceptor of the Asuras.

Beginning :

अस्य श्रीशुक्रमन्त्रस्य बार्हस्पत्य ऋषिः, शुक्रो देवता, त्रिष्टुप् छन्दः, मम शुक्रप्रसादसिद्ध्यर्थे जपे विनियोगः । श्रामित्यादिकरषडङ्गन्यासः ।

End :

ओं श्रां श्रीं श्रूं शुक्राय नमः, लक्षं जपः, दशांशहोमः । इति ॥

No. **7405.** शुक्रशापविमोचनमन्त्रः.

ŚUKRAŚĀPAVIMŌCANAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 62*b* of the MS. described under No. 5661, wherein it has apparently been omitted to be included in the list of other works.

Complete.

According to the Purāṇas, Śukra is said to have cursed liquor to the effect that the Brahmin who happens to drink it commits sin; and the repetition of this Mantra is intended to remove the power of the curse thus pronounced on liquor.

Beginning :

शुक्रशापविमोचनमहामन्त्रस्य शुक्र ऋषिः, देवी गायत्री छन्दः, शुक्रशापविमोचनार्थे जपे विनियोगः ।

End :

ऐं शुक्रशापविमोचनाय क्रीं अमोघाम्नाय सौः मोचय मोचय स्वाहा ।

ऐं शुक्रका(या)य विद्महे क्रीं कृष्णाय धीमहि । तन्नश्शुक्रः प्रचोदयात् । अष्टवारं जपित्वा ॥

No. **7406.** शुद्धमातृकान्यासः.

ŚUDDHAMĀTṚKĀNYĀSAḤ.

Pages, 2. Lines, 10 on a page.

Begins on fol. 192*b* of the MS. described under No. **124,** wherein it is found in the Daśavidhamātṛkānyāsa 192*a*, given therein in the list of other works.

Complete.

On the ceremonial touching of certain parts of the body, while repeating at the same time the series of Mantra-formulas obtained by introducing the successive letters of the alphabet between the words ओं and नमः. Ten Mātṛkānyāsas are mentioned herein and most of these have been explained already in the descriptive notices relating to them.

Beginning:

शिवादिसर्वमन्त्राणामादौ न्यासविधौ विधिः ।
दशधा मातृकान्याससिद्धिदश्शम्भुरब्रवीत् ॥
शुद्धं बिन्दुयुतं विसर्गसहितं हृल्लेखया श्रीयुतं
बालासंपुटितं तथैव परया श्रीविद्ययालङ्कृतम् ।
आरोहादवरोहतश्च सहितं न्यासं पुनर्हंसयोः
मालिन्या दशधा विभज्य कुरुते साक्षात्स एकश्शिवः ॥

तत्रादौ शुद्धमातृकाविधिर्लिख्यते—

अस्य श्रीशुद्धमातृकान्यासमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीशुद्धमातृका सरस्वती देवता, व्यञ्जनानि बीजानि, स्वराः शक्तयः, व्यक्तयः कीलकं, श्रीशुद्धमातृकान्यासे विनियोगः ।

End:

ओं अं (अ) नमः शिरसि । इति मातृकास्थानेषु न्यसेत् ॥

No. **7407.** शुद्धमातृकासरस्वतीमहामन्त्रः.

ŚUDDHAMĀTṚKĀSARASVATĪMAHĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 138*b* of the MS. described under No. 537. Complete.

Herein the Mantra-formulas obtained by introducing the successive letters of the alphabet between the Mantra-formula ऐं ह्रीं श्रीं and the word नमः are repeated during the ceremonial touching of certain parts of the body. This Nyāsa is intended to be a preliminary to the repetition of the Śrīvidyāmantra.

Beginning:

अस्य श्रीशुद्धमातृकासरस्वतीमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, शुद्धमातृका सरस्वती देवता, हलः बीजानि, स्वराश्शक्तयः, बिन्दवः कीलकं, ममोपास्यमानश्रीविद्याङ्गत्वेन शुद्धमातृकान्यासे विनियोगः ।

End:

ऐं ह्रीं श्रीं अ नमः इति क्ष नमः पर्यन्तम् ॥

No. **7408.** शुद्धविद्यामन्त्रः.

ŚUDDHAVIDYĀMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 274*a* of the MS. described under No. 5477, wherein it is found in the Mantramālikā 273*a* in the list of other works

Complete.

The repetition of this Mantra is intended to propitiate Siddhalakṣmī and to enable one to bring people under one's control.

Beginning:

अस्य श्रीशुद्धविद्यामन्त्रस्य इन्द्र ऋषिः, विराट् छन्दः, सिद्धलक्ष्मीर्देवता, ई बीजं, ककारः शक्तिः, श्रीसिद्धलक्ष्मीप्रीत्यर्थे विनियोगः ।

End:

कुरु कुरु आं क्रूं सुरासुरकन्यकां हुं फट् स्वाहा । क्लीं नमः, ह्रीं नमः, श्रीं नमः, पुनश्चरणं दशलक्षं कुर्यात् । दशांशतर्पणहोमः ॥

Colophon:

इति शुद्धविद्या ॥

No. 7409. शुद्धविद्यामन्त्रः.

ŚUDDHAVIDYĀMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol 9*b* of the MS. described under No. 5673, wherein it is found in the Āmnāyamantramālikā 1*a* in the list of other works.

Complete.

The repetition of this Mantra is intended to propitiate the goddess Suddhavidyāmbā, a manifestation of Dēvī, and thus to enable one to free one's soul from the bondage of Saṁsāra.

Beginning :

अस्य श्रीशुद्धविद्यामहामन्त्रस्य कर्मविपाकसदाशिव ऋषिः, गायत्री छन्दः, श्रीशुद्धविद्या मनोन्मनी देवता ; ऐं बीजं, ईं शक्तिः, औं कीलकं, मम पशुपाशविमोचनशुद्धविद्याम्बाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

मनुः—

ऐं ईं औं श्रीशुद्धविद्याम्बाश्रीपादुकां पूजयामि नमः ॥

No. 7410. शुद्धविद्यामन्त्रः.

ŚUDDHAVIDYĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 2*a* of the MS. described under No. 673, wherein it is found in the Ṣaḍāmnāya 1*a* in the list of other works.

Complete.

Similar to the above.

Beginning :

अस्य श्रीशुद्धविद्यामन्त्रस्य कर्मविपाकसदाशिव ऋषिः, गायत्री छन्दः, शुद्धविद्या मनोन्मनी देवता; ऐं बीजं, ईं शक्तिः, औं कीलकं, पशुपाशविमोचनार्थे जपे विनियोगः ।

End :

ओं ईं औः शुद्धविद्याम्बाश्रीपादुकां पूजयामि तर्पयामि नमः ॥

No. 7411. शुद्धविद्यामन्त्रः.
ŚUDDHAVIDYĀMANTRAḤ.

Pages, 2. Lines, 4 on a page.

Begins on fol. 26b of the MS. described under No. 2648, wherein it is found in the Āmnāyamantramālikā 16a in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशुद्धविद्यामहामन्त्रस्य कर्मविपाकसदाशिव ऋषिः, देवी गायत्री छन्दः; शुद्धविद्या देवता ; ऐं बीजं, ईं शक्तिः, औं कीलकं, इष्टार्थे विनियोगः ।

End:

महादेवि महामान्ये मनोन्मनि शुद्धविद्ये सकृदपि परिपाहि सुन्दरीं त्वां नमामि ।

ऐं ईं औं ॥

No. 7412. शुद्धविद्यामन्त्रः.
ŚUDDHAVIDYĀMANTRAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 228b of the MS. described under No. 124, wherein it is found in the Ṣaḍāmnāyamantra 228b in the list of other works

Complete.

Similar to the above

Beginning:

अस्य श्रीशुद्धविद्यामहामन्त्रस्य कर्मविपाकसदाशिव ऋषिः, गायत्री छन्दः, सुद्धविद्या मनोन्मनी देवता, ऐं बीजं, ईं शक्तिः, औं कीलकं, श्री-शुद्धविद्यामनोन्मनीप्रसाद—योगः ।

End:

ऐं ईं औं शुद्धविद्याम्बादिव्यश्रीपादुकां पूजयामि नमः ॥

No. **7413.** शुद्धशक्तिजयमालामन्त्रः.

ŚUDDHAŚAKTIJAYAMĀLĀMANTRAḤ.

Pages, 5. Lines, 18 on a page.

Begins on fol. 141*a* of the MS. described under No. 2961, wherein this and the Mantras described under Nos. 7414, 7415 and 7417 are all found in Śuddhaśaktimālā 131*a* in the list of other works.

Complete.

This Mantra is in praise of Śuddhaśakti, i.e., Śakti conceived as not being subject to any limiting conditions; and its repetition is considered to be efficacious in making one learned.

Beginning:

अस्य श्रीशुद्धशक्तिजयमालामन्त्रस्य वागिन्द्रियाधिष्ठायी अंशादित्य ऋषिः; पङ्क्तिश्छन्दः, मोक्षदह्रीङ्कारभट्टारकपीठस्थितहृदयनामकामेश्वराङ्क-निलयहृल्लेखा नाम ललिता महाभट्टारिका देवता, वाक्सिद्धौ विनियोगः।

End:

महामहाशये जय जय, महामहाश्रीचक्रनगरसाम्राज्ञि जय जय नमस्ते नमस्ते स्वाहा नमः। ओं श्रीं ह्रीं ऐं॥

Colophon:

शुद्धशक्तिमालामन्त्रः॥

No. **7414.** शुद्धशक्तितर्पणमालामन्त्रः.

ŚUDDHAŚAKTITARPAṆAMĀLĀMANTRAḤ.

Pages, 6. Lines, 18 on a page.

Begins on fol. 138*b* of the MS. described under No. 2961.

Complete.

The repetition of the several significant names of Śuddhaśakti followed by the pouring of libations of water is considered to have the power to enable one to enter into the subterranean regions and there accomplish one's desires.

Beginning:

अस्य श्रीशुद्धशक्तितर्पणमालामन्त्रस्य पाणीन्द्रियाधिष्ठायी अर्यमा-दित्य ऋषिः, बृहती छन्दः, भगदलकारभट्टारकपीठस्थितलक्षसारनाम-

कामेश्वराङ्कनिलया ललिता नाम ललिता भट्टारिका देवता, बिलसिद्धौ विनियोगः ।

End :

महामहाशयां तर्पयामि, महामहाश्रीचक्रनगरसाम्राज्ञीं तर्पयामि नमस्ते नमस्ते स्वाहा नमः । ओं श्रीं ह्रीं ऐं ॥

No. 7415. शुद्धशक्तिनमोमालामन्त्रः.
ŚUDDHAŚAKTINAMŌMĀLĀMANTRAḤ.

Pages, 5. Lines, **18** on a page.

Begins on fol. 134*a* of the MS. described under No. 2961.

Complete.

This Mantra is also addressed to Śuddhaśakti; and its repetition is held to have the power to bestow on one's sandals such mysterious powers as will enable them to convey one to any place in all the three worlds in the shortest possible time.

Beginning :

अस्य श्रीशुद्धशक्तिनमोमालामन्त्रस्य पा(श्विनिद्र)याधिष्ठायी मित्रादित्य ऋषिः, उष्णिक् छन्दः, राजसएकारभट्टारकपीठास्थित एकवीरनामकामेश्वरादिनिलया एकला नाम ललिता महाभट्टारिका देवता, पादुकासिद्धौ विनियोगः ।

End :

महामहानन्दायै नमः, महामहास्पन्दायै नमः, महामहाशयायै नमः, महामहाश्रीचक्रनगरसाम्राज्यै नमस्ते नमस्ते स्वाहा नमः । ओं श्री ह्रीं ऐं ॥

No. 7416. शुद्धशक्तिमालामन्त्रः.
ŚUDDHAŚAKTIMĀLĀMANTRAḤ.

Pages, 6. Lines, 6 on a page.

Begins on fol. 56*a* of the MS. described under No. 5686.

Complete.

This Mantra is in praise of Śuddhaśakti; and its repetition is considered to have the power to enable one to wield one's sword so successfully as to win sovereignty over the eighteen Dvīpas.

Beginning:

अस्य श्रीशुद्धशक्तिमालामन्त्रस्य उपस्थेन्द्रियाधिष्ठानवरुणादित्य ऋषिः, गायत्री छन्दः, सात्त्विकाहङ्कारभट्टारकपीठस्थितकामेश्वराङ्कानिलय-कामेश्वरी ललिता महाभट्टारिका देवता, खड्गादिसिद्धौ विनियोगः ।

End:

महामहास्कन्दे महामहाशये महाश्रीचक्रनगरसाम्राज्ञि नमस्ते नमस्ते स्वाहा । सौः क्लीं ऐं श्रीं ह्रीं ऐं ।

एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
अग्निवातमहाक्षोभे राज्ञो राज्यस्य विप्लवे ॥

* * * *

कामराजनियुक्तायै भवत्यै त्रिकोण्यै नमः ।
भूपस्थानप्रमाणोक्तं चक्ररूपं प्रकीर्तिताः ॥

Colophon:

इति शुद्धशक्तिमालास्तोत्रं सम्पूर्णम् ॥

No. 7417. शुद्धशक्तिस्वाहामालामन्त्रः.

ŚUDDHAŚAKTISVĀHĀMĀLĀMANTRAḤ.

Pages, 6. Lines, 18 on a page.

Begins on fol. 136a of the MS. described under No. 2961.

Complete.

The repetition of this Mantra, which is also addressed to Śuddhaśakti, is considered to have the power to enable one to find out the places containing hidden treasures.

Beginning:

अस्य श्रीशुद्धशक्तिस्वाहामालामन्त्रस्य पादेन्द्रियाधिष्ठायी धात्रादित्य ऋषिः, अनुष्टुप् छन्दः, तामसाहङ्कारभट्टारकपीठस्थित ईश्वरनामकामेश्व-राङ्कनिलया ईश्वरी नाम ललिता महाभट्टारिका देवता, अञ्जनसिद्धौ विनियोगः ।

End:

महामहास्पन्दायै स्वाहा, महामहाजयायै स्वाहा, महामहाश्रीचक्र-नगरसाम्राज्यै नमस्ते नमस्ते स्वाहा नमः। ओं श्रीं ह्रीं ऐं ॥

No. 7418. शूलिनीकवचः.
ŚŪLINĪKAVACAḤ.

Pages, 5. Lines, 18 on a page.

Begins on fol. 147*a* of the MS. described under No. 5673 wherein it is given as beginning on fol 146*a*.

Complete as found in the Ākāśabhairavakalpa.

The repetition of this Mantra is considered to have the power to enable one to realise the goddess Śūlinī and become one with her even in this life.

Beginning:

अथ वक्ष्यामि शूलिन्याः कवचं सर्वसिद्धिदम् ।
समाहितेन मनसा शृणु गुह्यं सनातनम् ॥

* * * *

कवचस्य ऋषिर्देव्या मृत्युञ्जय उदाहृतः ।
उष्णिक् छन्दस्तथा देवी देवता स्तवशूलिनी ॥
ओङ्कारबीजमित्युक्तं माया शक्तिस्ततः परम् ।
शूलिन्यात्मैक्यसिद्ध्यर्थे विनियोगो वरानने ॥

* * * *

जयेश्वर्यग्रतः पातु पृष्ठे मे विजयेश्वरी ।
अजिता वामतः पार्श्वे दक्षिणे त्वपराजिता ॥

End:

राष्ट्रमव्याहता पातु पूजां सर्ववशङ्करी ।
श्रीदेवी पातु धान्यं मे सर्वदा सर्वसम्पदा ॥

* * * *

शूलिन्याः कवचेनैव संवृतः पूज्यतेऽखिलैः ।
अनेनैव शरीरेण जीवन्मुक्तो भवेच्छिवे ॥

Colophon:

इति आकाशभैरवकल्पे उमामहेश्वरसंवादे शूलिनीकवचं सम्पूर्णम् ॥

No. **7419.** शूलिनीदिग्बन्धनमालामन्त्रः.

ŚŪLINĪDIGBANDHANAMĀLĀMANTRAḤ.

Pages, 5. Lines, 14 on a page.

Begins on fol. 152*b* of the MS. described under No. 5673.

Complete as found in the Ākāśabhairavakalpa.

The repetition of this Mantra is considered to have the power of protecting one from all possible dangers that may come from the various quarters and of driving off all evil spirits.

Beginning:

अस्य श्रीशूलिनीदुर्गादिग्बन्धनमालामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीशूलिनी महादुर्गा देवता; दुं बीजं, स्वाहा शक्तिः, फट् कीलकं, मम शूलिनीमहादुर्गाप्रसादेन अष्टदिग्बन्धने भूतनिग्रहार्थे जपे विनियोगः । ओन्नमो भगवते असिताङ्गभैरवाय ब्राह्मीमाहेश्वरीसहिताय इन्द्रदिशं बन्ध बन्ध मां रक्ष रक्ष ।

End:

शाकिनीहाकिनीडाकिनीसर्वदुष्टग्रहोच्चाटय(नि) ओं ह्रां ह्रीं ह्रुं फट् स्वाहा ॥

* * * *

सर्वारिष्टंप्रण(ष्टानि न) श्यन्ति सर्वत्र विजयी भवेत् ॥

Colophon:

इति दिग्बन्धनमन्त्रः ।

इति श्रीआकाशभैरवकल्पे शूलिनीदिग्बन्धनस्तोत्रं सम्पूर्णम् ॥

No. 7420. शूलिनीदुर्गापरमेश्वरीमन्त्रः.

ŚŪLINĪDURGĀPARAMEŚVARĪMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 56*a* of the MS. described under No. 29, wherein it is given as Śūlinīmantra in the list of other works.

Complete.

The repetition of this Mantra is considered to have the power to secure the grace of the goddess Śūlinī and to enable one to drive off evil spirits.

Beginning :

अस्य श्रीशूलिनीदुर्गापरमेश्वरीमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीशूलिनी दुर्गा परमेश्वरी देवता ; दुं बीजं, स्वाहा शक्तिः, श्रीशूलिनीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

पञ्चपूजा । मनुः—ज्वल ज्वल शूलिनि दुष्टग्रहं हुं फट् स्वाहा ॥

No 7421. शूलिनीदुर्गापरमेश्वरीमन्त्रः.

ŚŪLINĪDURGĀPARAMEŚVARĪMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 103*a* of the MS. described under No. 5452, wherein it is given as Śūlinīdurgāmantra in the list of other works.

Complete.

Similar to the above.

Beginning :

अस्य श्रीशूलिनीदुर्गापरमेश्वरीमन्त्रस्य दीर्घतम ऋषिः, ककुत् छन्दः, श्रीशूलिनी दुर्गा परमेश्वरी देवता ; दुं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, शूलिनीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

ओं ह्रीं ज्वल ज्वल शूलिनि दुष्टग्रहं हुं फट् स्वाहा ॥

त्रिपञ्चकोष्ठेषु विलिख्य शूलिनी ससाध्यनामाङ्कितमध्यबीजकम् ।
रेखाशिरःकल्पितशूलयुक्तं यन्त्रं महाभूतपिशाचहानिम् ॥

No. 7422. शूलिनीदुर्गापरमेश्वरीमन्त्रः.

ŚŪLINĪDURGĀPARAMĒŚVARĪMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 75*a* of the MS. described under No. 537, wherein it is given as Śūlinīmantra in the list of other works.

Complete.

Similar to the above

Beginning:

अस्य श्रीशूलिनीदुर्गापरमेश्वरीमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीशूलिनी दुर्गा परमेश्वरी देवता ; दुं बीजं, स्वाहा शक्तिः, श्रीशूलिनीदुर्गा . ग. ।

End:

पञ्चपूजा । मनुः—
ओं ज्वल ज्वल शूलिनि दुष्टग्रहं हुं फट् स्वाहा ॥

No. 7423. शूलिनीदुर्गापरमेश्वरीमन्त्रः.

ŚŪLINĪDURGĀPARAMĒŚVARĪMANTRAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 13*a* of the MS. described under No. 2854, wherein it is given as Śūlinīdurgāmantra in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीशूलिनीदुर्गापरमेश्वरीमहामन्त्रस्य ब्रह्मा ऋषि, गायत्री छन्दः, श्रीशूलिनी दुर्गा परमेश्वरी देवता ; दुं बीजं, स्वाहा शक्तिः, श्रीशूलिनीदुर्गापरमेश्वरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं श्रीं ह्रीं दुं ज्वल ज्वल शूलिनि दुष्टग्रहं हुं फट् स्वाहा ॥
पञ्चपूजां कृत्वा ॥

No. 7424. शूलिनीदुर्गामहामन्त्रः.
ŚŪLINĪDURGĀMAHĀMANTRAḤ.

Pages, 2. Lines, 14 on a page.

Begins on fol. 169a of the MS. described under No. 5673, wherein it is given as Śūliniṣaṭprayōgamantra.

Complete.

This Mantra is in praise of Śūlinīdurgā, i.e., Durgā conceived as having a Śūla in her hand; and its repetition is considered to be efficacious in bringing about the attainment of the four Puruṣārthas or principal aims of life.

Beginning:

अस्य श्रीशूलिनीमहामन्त्रस्य बृहत्त(म)ऋषिः, उष्णिक् छन्दः, श्रीशूलिनी दुर्गा देवता, दुं बीजं, स्वाहा शक्तिः, फट् कीलकं, श्रीशूलिनीदुर्गाप्रसादेन चतुर्विधपुरुषार्थे जपे विनियोगः ।

End:

वं अमृतात्मने अमृतनैवेद्यं परिकल्पयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

Colophon:

शूलिनी(मन्त्रः) समाप्तः ॥

No. 7425. शूलिनीमन्त्रः.
ŚŪLINĪMANTRAḤ.

Page, 1 Lines, 6 on a page.

Begins on fol. 4b of the MS. described under No. 5832.

Complete.

Similar to the above.

Considered to be efficacious in causing the accomplishment of one's desires.

Beginning:

आं आं ह्रीं सौः ऐं क्लीं ह्रौं ग्लौं श्रीं क्रों शूलिनिदुर्गायै चण्डपराक्रमायै ।

End:

आवेशय आवेशय अमलवरयूं फट् स्वाहा ॥
इत्येनच्छूलिनीमन्त्रं(न्त्र)सहस्रं सिद्धिमाप्नुयात् ।
यं यं वापि स्मरेज्जप्त्वा तत्तत्प्राप्नोति निश्चितम् ॥

No. **7426.** शूलिनीमालामन्त्रः.

ŚŪLINĪMĀLĀMANTRAḤ.

Pages, 12. Lines, 5 on a page.

Begins on fol. 12*a* of the MS. described under No. 775, wherein it is given as Śūlinīmantra in the list of other works.

Complete.

This Mantra is also in praise of the goddess Śūlinī, and its due repetition is considered to have the power to counteract the evils caused by hostile spirits, and to confer on one health, wisdom and prosperity.

Beginning:

फट् ज्वल स्वाहा, शूलिनि ज्वल हुं दुष्टग्रहप्रतिक्रियायै स्वाहा, ज्वल ज्वल दुष्टग्रहशूलिनि फट् हुं ह्रीं ओं नमो भगवति सहस्रकोटि-कालानलसमप्रभे पञ्चमुखवाहिनि ज्वालाकेशिनि ।

End:

वाग्गुदादिसर्वेन्द्रियप्रेरकं जीवय जीवय चैतन्यं वर्धय वर्धय मोदय मोदय सर्वैश्वर्यसमृद्धिं कुरु कुरु ह्रीं श्रीं क्ष्यूं स्वाहा ॥

No. **7427.** शूलिनीमालामन्त्रः.

ŚŪLINĪMĀLAMANTRAḤ.

Pages, 1. Lines, 14 on a page.

Begins on fol. 152*a* of the MS. described under No. 5673.

Complete.

Similar to the above.

Beginning:

ओं नमो भगवति सहस्रकोटिकालानलसमप्रभे पञ्चमुखवाहिनि ज्वालाकेशिनि करालदंष्ट्रवदने कालोरगविभूषितावयवे कालकालरूपिणि ।

End:

सर्वेन्द्रियप्रेरकं जीवय जीवय तस्य चैतन्यं वर्धय वर्धय मोदय मोदय तस्य देह[म]रोग्यं कुरु कुरु ह्रीं श्रीं क्रों स्वाहा हुं फट् ॥

No. 7428. शूलिनीमालामन्त्रः.

SŪLINĪMĀLĀMANTRAḤ.

Page, 1. Lines, 14 on a page.

Begins on fol. 149*b* of the MS. described under No. 5673, wherein it has been apparently omitted to be included in the list of other works.

Complete.

Similar to the above.

Beginning and **End:**

आ नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहारकारि जातवेदी ज्वलन्ती ज्वल ज्वल प्रज्वल प्रज्वल ह्रां ह्रीं ह्रूं ठ ठ ठ ठ ठ ठ ठ ज्वालामालिनि हुं फट् स्वाहा। आं क्षौं चित्रायै नमः ॥

No. 7429. शूलिनीहृदयम्.

ŚŪLINĪHṚDAYAM.

Pages, 6. Lines, 14 on a page.

Begins on fol. 149*b* of the MS. described under No. 5673, wherein it is wrongly stated in the list of other works as beginning on fol. 149*a*.

Complete.

According to the colophon at the end of the work, it forms the 16th Adhyāya of the Śarabhasālvapakṣirājakalpa which is a portion of the Ākāśabhairavakalpa of the Mahāśaivatantra. This work is ascribed to Śaṅkara.

The proper repetition of this Mantra which is said to be the most important of the Mantras relating to Śūlinī is considered

to have the power to enable a person to know everything, to accomplish all his desires and to become Śiva himself.

Beginning:

श्रीपार्वत्युवाच—

सर्वज्ञ भगवन् शम्भो सर्वसूक्ष्मैकबोधक ॥
त्रि(श्री)शूलिन्या महादेव्या हृदयं कथयस्व मे ॥

श्रीशिवः—

साधु कल्याणि वक्ष्यामि सर्वसूक्ष्मैकसूक्ष्मकम् ।
यस्य स्मरणमात्रेण मन्त्रवित्सर्वविद्भवेत् ॥

* * * *

हृदयं तोदकं ज्ञेयं विश्वस्यायतनं मनोः ।
तस्मात्सहृदयो मन्त्रः साक्षाद्ब्रह्मानुभूतिदः ॥

End:

तस्य वीर्यशरीरस्य विश्वातीतस्य मन्त्रिणः ।
विश्वप्रकाशरूपस्य किमसाध्यं सुखात्मनः ॥

इति देशिक(ज्ञ)या परमशूलिनीमनुबीजयोर्हृदयं क्रमात् प्रसमीक्ष्य तत्पारभावयेत् स शिवो भवति स शिवो भवति ॥

Colophon:

इति श्रीमहाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शङ्करेण विरचिते शरभसाल्वपक्षिराजकल्पे दुर्गाविश्वापालनविधाने शूलिनीहृदयं नाम षोडशोऽध्यायः ॥

No. 7430. शेषषडक्षरमन्त्रः.

ŚĒṢAṢAḌAKṢARAMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 26*b* of the MS. described under No. 5786.

Complete.

The repetition of this Mantra, which consists of six syllables, is intended to propitiate the divine serpent, Śēṣa.

Beginning :

ओं शें शेषाय नमः इति प्राणायामः १२.

* * * *

अस्य श्रीशेषषडक्षरमन्त्रस्य सनत्कुमार ऋषिः, गायत्री छन्दः, श्रीशेषो देवता, शेषप्रेरणया शेषप्रीत्यर्थे शेषषडक्षरमन्त्रजपे विनियोगः ।

End :

ओं शें शेषाय नमः ओं इति जपः । उपसंहारः पूर्ववत् ॥

No **7431.** श्यामलाकवचः.

ŚYĀMALĀKAVACAḤ.

Pages, 5. Lines, 14 on a page.

Begins on fol. 175*a* of the MS. described under No. 5673, wherein it has been omitted to be given in the list of other works; Śyāmalāmātṛkānyāsa is therein wrongly stated as beginning on fol. 175*a*. It begins on fol. 170*b* and is described under the next number under the name Śyāmalāpūrvāṅganyāsa.

Complete as found in the Mahārṇavāgama

This Kavacamantra is addressed to the goddess Śyāmalā or Mātaṅgī; and its repetition accompanied by due reverence, homage and service to one's Guru is considered to have the power to enable one to become a king and to obtain salvation.

Beginning :

शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं परम् ।
गोपनीयं प्रयत्नेन मौनेन जपमाचरेत् ॥

* * * *

ब्रह्मरन्ध्रे सदा पायात् श्यामला मन्त्रनायिका ।
ललाटं रक्षतां नित्यं कदम्बेशी सदा मम ॥

End :

तथा तु कवचं देव्यास्सफलं गुरुसेवया ।
इह लोके नृपो भूत्वा पठन्मुक्तो भविष्यति ॥

* * * *

दद्याद्गुरुः सुशिष्याय गुरुभक्तिपराय च ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥

Colophon :

इति महार्णवे श्यामलाकवचं सम्पूर्णम् ॥

No. **7432.** श्यामलापूर्वाङ्गन्यासः.
ŚYĀMALĀPŪRVĀṄGANYĀSAḤ.

Pages, 10. Lines, 14 on a page.

Begins on fol. 170*b* of the MS. described under No. 5673, wherein it is given as Śyāmalāmātṛkānyāsa and is wrongly stated in the list of other works as beginning on fol. 175*a*.

Complete.

On the ceremonial touching of certain parts of the body while repeating certain Mantras relating to Śyāmalā, as a preliminary to the worship of that goddess.

Beginning :

अकारादिक्षकारान्तन्यासकरणे स्थानानि । आननवृत्तअक्षिश्रुतिनासागण्डोष्ठदन्तमूर्ध्न्याश्वे(धास्य)दोःपत्सन्ध्यङ्गुल्यग्रेषु पार्श्वद्वयपृष्ठनाभिजठरेषु हृद्दोर्मूलापरगलकक्षहृदादिपाणिपादयुगे जठराननयोर्व्यापकमित्यक्षरान् क्रमश इत्थं युक्तस्थानेषु सबिन्दुकान्मातृकावर्णान्विन्यसेदिति बहिर्मातृका ।

End :

शोणाङ्कुशोज्ज्वलां नौमि वीणावादविनोदिनीम् ।
एवं ध्यात्वा महादेवीं मानसैरुपचारकैः ॥
पूजयित्वा विधानेन जप्त्वा मूलं स्वशक्तितः ।
देव्यै जपं निवेद्याथ गुर्वादीन् प्रणमेदिति ॥

Colophon :

इति पूर्वाङ्गपद्धतिः समाप्ता ॥

No. 7433. श्यामलामन्त्रः.

ŚYĀMALĀMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 135*b* of the MS. described under No. 537.

Complete.

Herein the goddess Śyāmalā is conceived as a Guru, and the Mantra is addressed to the holy sandals worn by the goddess. It is considered to have the power to enable one to make people become spell-bound and deprived of all physical and mental powers and thus bring them under one's magic control and influence.

Beginning :

अस्य श्रीश्यामलागुरुपादुकामन्त्रस्य मतङ्गभगवानृषिः, गायत्री छन्दः, श्यामलागुरुपादुका देवता ; ऐं क्लीं सौः इति बीजं, हसक्षमिति शक्तिः, स ह कीलकं, श्यामलागुरुपादुकाप्रीत्यर्थे जपे विनियोगः ।

End :

सर्वेषां सर्ववाक्चित्तचक्षुर्मुखगतिजिह्वास्तम्भनं कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्लौं ठः ठः ठः ठः हुं फट् ॥

No. 7434. श्रीकण्ठादिमातृकान्यासः.

ŚRĪKAṆṬHĀDIMĀTṚKĀNYĀSAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 115*a* of the MS. described under No. 675.

Complete.

On the ceremonial touching of certain parts of the body while repeating at the same time the Mantra-formulas formed by the combination of the successive letters of the alphabet with certain names denoting Śiva and Śakti.

Beginning :

अस्य श्रीकण्ठादिमातृकान्यासमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः, गायत्री छन्दः, श्रीकण्ठादिमातृका सरस्वती देवता ; हलो बीजानि,

स्वराश्शक्तयः, बिन्दवः कलिकं, श्रीकण्ठादिमातृकाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

हं कुलिशमहालक्ष्मीभ्यां नमः, ळं शिवेशव्यापिनीभ्यां नमः, क्षं संवर्तकेशमायाभ्यां नमः—इति मातृकाव्यापकं न्यसेत् ॥

Colophon:

इति श्रीकण्ठा(दि)मातृकान्यासः ॥

No. 7435. श्रीकमलासंपुटितमातृकान्यासः.

ŚRĪKAMALĀSAṀPUṬITAMĀTṚKĀNYĀSAḤ

Pages, 2. Lines, 9 on a page.

Begins on fol. 193a of the MS. described under No. 124, wherein it is found in Daśavidhamātṛkānyāsa 192a given in the list of other works.

Complete.

On the ceremonial touching of certain parts of the body while repeating at the same time the series of Mantra-formulas obtained by introducing the syllable श्रीं before and after each of the successive letters of the alphabet coupled with the word नमः.

Beginning:

अथ लक्ष्मीमातृकान्यासः—

अस्य श्रीकमलासम्पुटितमातृकामन्त्रस्य भृगुः ऋषिः, गायत्री छन्दः, श्रीकमलाम्बा देवता, शं बीजं, ईं शक्तिः, रेफः कीलकं, श्रीकमलामातृकान्यासे विनियोगः ।

End:

श्रीं अं नमः श्रीं इत्यादि क्षान्तं न्यसेत् ॥

Colophon:

इति कमलासम्पुटितमातृकान्यासः ॥

No. **7436.** श्रीकराष्टाक्षरमन्त्रः.
ŚRĪKARĀṢṬĀKṢARAMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 9*a* of the MS. described under No. 5786.

Complete.

Ther epetition of this eight-syllabled Mantra is considered to have the power to enable one to secure the favour of Lakṣmīnārāyaṇa.

Beginning :

उत्तिष्ठ श्रीकर स्वाहा ओं इति प्राणायामः १२.

* * *

अस्य श्रीश्रीकराष्टाक्षरमहामन्त्रस्य ब्रह्मा ऋषिः, जगती छन्दः, श्रीलक्ष्मीनारायणो देवता, श्रीलक्ष्मीनारायणप्रेरणया श्रीलक्ष्मीनारायणप्रीत्यर्थे श्रीकराष्टाक्षरमहामन्त्रजपे विनियोगः ।

End :

ओं उत्तिष्ठ श्रीकर स्वाहा ओं इति जपः । उपसंहारः पूर्ववत् ॥

No. **7437.** श्रीचक्रन्यासकवचः.
ŚRĪCAKRANYĀSAKAVACAḤ.

Pages, 5. Lines, 7 on a page.

Begins on fol. 104*b* of the MS. described under No. **673**, wherein it is given as Cakranyāsakavaca in the list of other works.

Complete as found in the 33rd Paṭala of the Kāmēśvaratantra.

The due repetition of this Mantra, after having conceived one's body to be devoid of all fleshly forms and to be as brilliant as the blazing fire at the time of the universal dissolution, is considered to be efficacious in bringing about joy and the salvation of soul-emancipation.

Beginning :

कैलासशिखरासीनं शिवं पप्रच्छ पार्वती ।
श्रीचक्रन्यासकवचं ब्रूहि मे देव शङ्कर ॥

ईश्वर उवाच—

साधु पृष्टं त्वया देवि लोकानां हितकाम्यया ।
श्रीचक्रन्यासकवचं प्रस्फुटं कथयामि ते ॥
शरीरं चिन्तयेदादौ निजश्रीचक्ररूपकम् ।
त्वगाद्याकारनिर्मुक्तं ज्वलत्कालाग्निसन्निभम् ॥
द्वादशान्तं महापद्मे शिवशक्त्यात्मकं गुरुम् ।
परं तेजोमयं ध्यायेद्भोगमोक्षवराप्तये ॥
गणेशः पातु मे जानुं वामांसं क्षेत्रपालकः ।
दुर्गा तु दक्षिणं जानुं स्कन्धं वटुकभैरवः ॥

* * * *

End :

चक्रेश्वरी महादेवी सिद्धमुद्रासमन्विता ।
आपादमस्तकं पातु श्रीमत्त्रिपुरभैरवी ॥
इति श्रीचक्रराजस्य न्यासस्त्रैलोक्यमोहनं(नः) ।
कथितस्त्वयि वात्सल्याद्रहस्योऽपि वरानने ॥

Colophon :

इति कामेश्वरतन्त्रे बहुमहाष्टकप्रस्तारे नित्याषोडशार्णवे श्रीचक्रन्यासकवचं नाम त्रयस्त्रिंशः पटलः ॥

No **7438.** श्रीचिदम्बरपञ्चाक्षरीरुद्राम्बिकामहामन्त्रः.

SRĪCIDAMBARAPAÑCĀKṢARĪRUDRĀMBIKĀMAHĀ-MANTRAḤ

Pages, 2. Lines, 9 on a page.

Begins on fol. 13*a* of the MS. described under No. 2854, wherein it has been omitted to be included in the list of other works.

Complete

This five-syllabled Mantra is addressed to Śiva and Ambikā; and its repetition is believed to have the power to dispel all fears of rebirth.

Beginning :

अस्य (श्री)श्रीचिदम्बरपञ्चाक्षरीरुद्राम्बिकामहामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, चिदम्बरपञ्चाक्षरी रुद्राम्बिका देवता, ह्रीं बीजं, वां शक्तिः, विनियोगः ।

End :

ओं श्रीं ह्रीं न म वा शि य . . . .
सर्वेन्द्रियाणि मोहय सर्वसंमोहिनि जन्ममृत्युभयनाशिनि आवेशि(विश) आतिष्ठ आक्रोश अ[ ]शब्दकथिताय स्वाहा ॥

No. **7439.** श्रीमन्त्रः.

ŚRĪMANTRAḤ.

Pages, 2. Lines, 19 on a page.

Begins on fol. 323 of the MS. described under No. 5477, wherein it is found in the Mantramālikā 273a in the list of other works.

Complete.

This Mantra is addressed to Lakṣmī; and its repetition followed by certain ceremonial acts is considered to be efficacious in conferring wealth and prosperity on one. It has also the power to bring other people under one's control and influence.

Beginning :

अस्य श्रीश्रीमन्त्रस्य ऋचगायत्री छन्दः, लक्ष्मीर्देवता ; शं बीजं, ई शक्तिः, रं कीलकं, श्रीमित्यादिषडङ्गन्यासः ।

End :

श्रीं द्वादशलक्षं जपः । दशांशं त्रिमधुरयुक्तं सरोजैर्वा तिलैर(लै)-र्वा बिल्वैर्वा सत्समिद्भिर्वा कान्ति(भि)र्वा होमं कुर्यात् ।

* * * *

सघृतैरुपेतं तण्डुलं सकलवश्यतमम् ॥

No. 7440. श्रीविद्यान्यासः.
ŚRĪVIDYĀNYĀSAḤ.

Pages, 7. Lines, 10 on a page.

Begins on fol 177*b* of the MS. described under No. 124.

Complete.

On the ceremonial touching of certain parts of the body while repeating the syllables ऐं, सौं, क्लीं as a preliminary to the proper use of the Śrīvidyāmantra.

Beginning:

तत्रादौ विद्यान्यासः—

अस्य(ाः) श्रीविद्यायाम्(ः)आनन्दभैरव ऋषिः, दैवी गायत्री छन्दः, श्रीमहात्रिपुरसुन्दरी देवता, मूलाधारे ऐं बीजाय नमः, पादौ(दे) सौः शक्तये नमः, हृदि क्लीं कीलकाय नमः, करसम्पुटे श्रीविद्याङ्गत्वेन करशुद्धिन्यासे विनियोगः।

End:

महासौभाग्यजननि महामोक्षप्रदशक्तिसच्चिदानन्दपरब्रह्मस्वरूपिणी श्रीमहात्रिपुरसुन्दर्यम्बाश्रीपा—इति मूर्धादिपादान्तं त्रिर्व्यापकं विन्यस्य ततः क्लीमित्युच्चार्य शक्त्युत्थापनमुद्रां प्रदर्श्य ह्रीमित्यनेन मुञ्चेत् ॥

No. 7441. श्रीविद्यान्यासः.
ŚRĪVIDYĀNYĀSAḤ.

Pages, 16. Lines, 24 on a page.

Begins on fol 131*a* of the MS. described under No. 5643

Complete.

Similar to the above.

Beginning:

कारणात्प्रसृतं न्यासं दीपाद्दीपमिवोदितम् ।
एवं विन्यस्य देवेशि स्वाभेदेन विचिन्तयेत् ॥
ततश्च करशुद्ध्यादिन्यासं कुर्यात्समाहितः ।

तत्रादौ विद्यान्यासः—

अस्याः श्रीविद्यायाः आनन्दभैरव ऋषिः, दैवी गायत्री छन्दः, श्रीमहात्रिपुरसुन्दरी देवता, मूलाधारे ऐं बीजाय नमः, पादौ(दे) सौः शक्तये नमः, हृदि क्लीं कीलकाय नमः, करसम्पुटे श्रीविद्याङ्गत्वेन करशुद्धिन्यासे विनियोगः ।

End:

जगदाकर्षणकरीं जगत्कारणरूपिणीम् ।
सर्वमन्त्रमयीं नित्यां परमानन्दनन्दिताम् ॥
बालार्कमण्डिताभासं(न्तां) चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥

No. **7442.** श्रीविद्यामन्त्रः.

ŚRĪVIDYĀMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 159*a* of the MS. described under No. 537.

Incomplete.

On details connected with the repetition of the fifteen-syllabled Śrīvidyāmantra addressed to the goddess Tripurasundarī, the presiding deity of this Mantra.

Beginning:

ह्रां इति नेत्रमन्त्रेण निरीक्षणं, ह्रः इत्यस्त्रमन्त्रेण सम्प्रोक्षणं, ह्रः इत्यस्त्रमन्त्रेण दर्भैस्ताडनं, मूलमन्त्रेण सम्प्रोक्षणं, तत्रासनं परिस्तीर्य, तत्र पद्मं विलिख्य, तत्रोपविश्य उत्तिष्ठन्तु—रभे ।

End:

ममोपात्तदुरितक्षयद्वारा श्रीमहात्रिपुरसुन्दरीमुद्दिश्य श्रीमहात्रिपुरसुन्दरीदेवताप्रीत्यर्थं श्रीविद्यापञ्चदशाक्षरीमन्त्रजपं करिष्ये . . . . तेजोमयं ध्यात्वा ततो मूलमन्त्रेण प्राणायामत्रयं कृत्वा.

No. 7443. श्रीविद्यामालामन्त्रः.
ŚRĪVIDYĀMĀLĀMANTRAḤ.

Pages, 10. Lines, 7 on a page.

Begins on fol. 21*a* of the MS. described under No. 6274.

Complete.

This Mantra is in praise of the goddess Lalitā who is the presiding deity of this Mantra; and its repetition is believed to have the power to enable one to tide over great calamities.

Beginning:

श्रीविद्यामालामन्त्रस्य वरुणादित्य ऋषिः, गायत्री छन्दः, ललिता देवता, ऐं ह्रीं श्रीं ऐं क्लीं सौं नमः त्रिपुरसुन्दरि हृदयदेवि शिरोदेवि शिखादेवि कवचदेवि मन्त्रदेवि अस्त्रदेवि कामेश्वरि भगमालिनि ।

End:

महाश्रीचक्रनगरसाम्राज्ञि नमस्ते नमस्ते नमस्ते स्वाहा । सौं क्लीं ऐं (श्रीं) ह्रीं ऐं ॥

एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
अग्निबाधामहाक्षोभे राजराज्यस्य विप्लवे ॥

* * * *

एकवारजपन्त्रेन(पादेव) नित्यपूजाफलं लभेत् ॥

No. 7444. षट्स्थलब्रह्मषडक्षरमन्त्रः.
ṢAṬSTHALABRAHMAṢAḌAKṢARAMANTRAḤ.

Pages, 3. Lines, 14 on a page.

Begins on fol. 48*b* of the MS. described under No. 5673, wherein it is found in the Āmnāyamantramālikā in the list of other works.

Complete.

The six-syllabled Mantra-formula herein referred to is ओं वाय शि नमः which is held to denote Śiva conceived as the Supreme Brahman. Six parts of Śiva's body are represented by this formula: His face by the letter ओं, His two hands by the letters

वा and य, His body by the letter शि, and His legs by the letters न and मः.

Beginning:

अस्य श्रीषट्स्थलब्रह्मषडक्षरीमहामन्त्रस्य परब्रह्म ऋषिः, शैवगायत्री छन्दः, शिवो देवता, माहेश्वरी शक्तिः, ह्रीं बीजं, ह्रौं कीलकं, मम षट्स्थलब्रह्मषडक्षरीप्रसादासिद्ध्यर्थे विनियोगः ।

End:

चैतन्यं शाश्वतं स्वं (शान्तं) व्योमातीतं निरञ्जनम ।
नादबिन्दुकलातीतं [illegible] ॥
अवाच्यात्मस्वरूपाय शिवभावप्रदायिने ।
नमस्सद्गुरुनाथाय षट्स्थलब्रह्ममूर्तये ॥

No. **7445.** षट्स्थलब्रह्मषडक्षरमन्त्रः.

ṢAṬSTHALABRAHMAṢAḌAKṢARAMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 34*a* of the MS. described under No. 217, wherein it is given as Ṣaḍakṣaranyāsa in the list of other works

Complete.

Similar to the above.

Held to be efficacious in bringing about the joy of final beatitude.

Beginning:

अस्य श्रीषट्स्थलब्रह्मषडक्षरीमहामन्त्रस्य देवी गायत्री छन्दः, परमशिवो देवता, ओं बीजं, नमश्शक्तिः, आयेति कीलकं, षट्स्थलब्रह्मनिर्वाणसुखसंपदवाप्त्यर्थं षडक्षरीमन्त्रजपे विनियोगः ।

End:

षट्स्थलब्रह्मरूपिणि षडक्षरीमन्त्रदेवते जननि षट्स्थलभक्तिप्रसादपरमसुखैकप्रदेशे नमस्तुभ्यम् ।

चैतन्यं परिपूर्णमेकममलं ज्योतिर्मयं व्यापकं
तत्पञ्चाक्षरमन्त्रमाद्यममलं सूक्ष्मातिसूक्ष्मं परम् ।
लिङ्गं ब्रह्म सनातनं सुमनसा ध्यातव्यरूपं सदा
बाह्याभ्यन्तरसंस्थितं परशिवं प्राणेश्वरं भावयेत् ॥
अवाच्यात्मस्वरूपाय शिवभावप्रदायिने ।
नमस्सद्गुरुनाथाय षट्स्थलब्रह्ममूर्तये ॥

No. **7446**. षडाम्नायमन्त्रः.

ṢAḌĀMNĀYAMANTRAḤ.

Pages, 27. Lines, 5 on a page.

Begins on fol. 1*a* of the MS. described under No 5572.

Incomplete.

A collection of Mantras which are said to be worthy of begin repeated and contemplated upon. The six Āmnāyas are (1) Pūrvāmnāya, (2) Dakṣiṇāmnāya, (3) Paścimāmnāya, (4) Uttarāmnāya, (5) Ūrdhvāmnāya. (6) Anuttarāmnāya

Beginning:

नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
विश्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥

अथ षडाम्नायः । तत्र पूर्वाम्नायः—

अस्य श्रीशुद्धविद्यामन्त्रस्य कर्मविपाकसदाशिव ऋषिः, देवी गायत्री छन्दः, शुद्धविद्या मनोन्मनी देवता; ऐं बीजं, ईं शक्तिः, औः कीलकं, शुद्धविद्या . . . . . . योगः ।

End:

अं क्षः सौः शिवशक्तिसदाशिवेश्वरशुद्धविद्यामायाकलाविद्यारागकालनियतिपुरुषप्रकृत्यहङ्कारबुद्धिमनस्त्वक्चक्षुश्श्रोत्रजिह्वाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलपृथिव्यात्मकश्रीस्वप्रकाश.

स्फुरति यत्तव रूपमनुत्तरं स्फुरति यच्च जगन्मयमाम्बिके ।
उभयमेतदनुस्मरतां सतामभयदं . . . . . ॥
यत्र तेजांसि तेजांसि तमांसि च तमस्स्फुटम् ।
तेजांसि च तमांस्येतत् द्वन्द्वज्योतिरनुत्तरम् ॥

No. 7447. षडाम्नायमन्त्रः.

ṢAḌĀMNĀYAMANTRAḤ.

Pages, 22 Lines, 18 on a page.

Begins on fol. 105*a* of the MS. described under No. 5593

Complete.

Similar to the above.

Beginning:

ऐं ह्रीं श्रीं हं सश्शिवस्सो हं स्वरूपनिरूपणहेतवे आनन्दशुकानन्दनाथ-स्वगुरुसंविद्देव्यम्बाश्री, ऐं ह्रीं श्रीं सो हं हं सश्शिवस्स्वच्छन्दप्रकाशानन्दग-गनानन्दनाथपरमगुरुसंविद्देव्यम्बाश्री, ऐं ह्रीं श्रीं हं सश्शिवस्सो हं हं सस्स्वात्मारामपञ्जरलीनतैजसकृष्णानन्दनाथपरमेष्ठिगुरुश्री, ओं ह्रीं हं सस्सो हं स्वाहा अमुकानन्दनाथसंविद्देव्यम्बाश्री ॥

आदौ शिवो गुरुः प्रोक्तः पश्चाच्चैव सदाशिवः ।
नमाम्यहं गुरून् भक्त्या पश्चादीशः प्रकीर्तितः ॥

* * * *

End:

अनुत्तराम्नायस्समाप्तः ॥

नारायणं त(ध)मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च ।
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥
श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् ।
तं त्रोटकं वार्त्तिककारमन्यानस्मद्गुरून् सन्ततमानतोऽस्मि ॥

Colophon:

इति षडाम्नायस्समाप्तः ॥

No. **7448.** षडाम्नायमन्त्रः.

ṢAḌĀMNĀYAMANTRAḤ.

Pages, 27. Lines, 16 on a page.

Begins on fol. 1*a* of the MS. described under No. 5560.

Complete.

Same as the above.

No. **7449.** षडाम्नायमन्त्रानुक्रमणिका.

ṢAḌĀMNĀYAMANTRĀNUKRAMAṆIKĀ.

Pages, 8. Lines, 4 on a page.

Begins on fol. 31*a* of the MS. described under No. 2848.

Complete.

Gives a list of the subordinate Mantras contained in the Ṣaḍāmnāyamantra.

Beginning:

गुरुत्रयम्— गुरु-परमगुरु-परमेष्ठिगुरवः । गणपतिः — महागणपतिरेकः । पीठत्रयम्— कामगिरिपीठं, पूर्णगिरिपीठं, जालन्धरपीठम् । इति पूर्वाम्नायगुरवो मूलाधारस्थाः ।

End:

रघुनाथाश्रमानन्दनाथ, सत्यानन्दनाथ—इत्यु(त्यनु)त्तराम्नायगुरून् आज्ञायां मनश्चक्रे च पूजयेत् ॥

No. **7450.** षोढान्यासः.

ṢŌḌHĀNYĀSAḤ.

Pages, 7. Lines, 10 on a page.

Begins on fol. 244*b* of the MS. described under No. 124, wherein it is given as Gaṇēśādiṣōḍhānyāsa in the list of other works.

Complete.

On six different kinds of ceremonial touching of certain parts of the body while repeating at the same time the appropriate Mantras relating to Gāṇēśa, the Navagrahas, the 27 Nakṣatras, the

Yōginīs, the twelve Rāśis and the three Pīṭhas respectively. These six Nyāsas are generally called (1) Gaṇēśa-nyāsa, (2) Graha-nyāsa, (3) Nakṣatra-nyāsa, (4) Yōginī-nyāsa, (5) Rāśī-nyāsa, (6) Pīṭha-nyāsa. The observance of these Nyāsas is considered to be a necessary preliminary ceremonial to the repetition of the Śrīvidyāmantra.

Beginning:

अस्य श्रीगणेशादिषोढान्यासस्य, दक्षिणामूर्तिः ऋषिः, पङ्क्तिश्छन्दः, श्रीमातृका त्रिपुरसुन्दरी देवता, मम उपास्यश्रीविद्याङ्गत्वेन सर्वसिद्धिसाधने विनियोगः ।

End:

बिन्दुरहङ्कारात्मा रविरेतन्मिथुनसमरसाकारः ।
कामः कमनीयतया क(प्रका)शदहसे(ने)न्दुविग्रहः (?) ॥
इति कामकलाविद्या देवीचक्रात्मिका सेयम् ।
विदितो येन . . . . भवति महात्रिपुरसुन्दरीरूपः ॥

No. **7451.** षोडशाक्षरन्यासः.

ṢŌḌAŚĀKṢARANYĀSAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 61*b* of the MS. described under No. 2886.

Complete.

On the ceremonial touching of certain specified parts of the body while repeating at the same time the letters of the sixteen-syllabled Śrīvidyāmantra क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं.

Beginning:

ऐं ह्रीं श्रीं अं मध्यमा २ आं अनामिका २ सौः कनिष्ठि २ अं अङ्गुष्ठा २ अं तर्जनी २ सौः करतल इति करशुद्धिन्यासः ।

End:

शिरोललाटमूर्धहृदयस्तनद्वयकुक्षि[द्वय]नाभि[द्वय]मूलाधारजानुद्वयजङ्घाद्वयपादद्वयमूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्धाज्ञाबिन्दूर्ध्वबिन्दुनादब्रह्मरन्ध्रेषु पञ्चप्रणवपूर्वकं नमोऽन्तेन न्यसेत् ॥

Colophon:

इति षोडशाक्षरन्यासः ॥

No **7452.** षोडशाक्षरमन्त्रः.

SOḌAŚĀKṢARAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 24*a* of the MS. described under No. 775, wherein it is given as Śrīvidyāṣōḍaśākṣarīmantra in the list of other works

Complete.

The repetition of this Mantra-formula consisting of 16 syllables, as coupled with the Bālāmantra-formula, etc., is considered to have the power to propitiate Tripurasundarī.

Beginning:

अस्य श्रीविद्याषोडशाक्षरीमहामन्त्रस्य दक्षिणामूर्त्यानन्दभैरवादय ऋषयः, गायत्र्यादीनि छन्दांसि, महाराजराजेश्वरी महात्रिपुरसुन्दरी परा शक्तिर्देवता ; श्रीं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, नाभिगुह्योदरेषु क्रमेण विन्यसेत् । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं ह्रीं ओं सौः ऐं क्लीं ह्रीं (श्रीं)ओं ॥

No. 7453. षोडशाक्षरमन्त्रः.
ṢŌḌAŚĀKṢARAMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 172*a* of the MS. described under No. 124, wherein it is given as Lalitāṣōḍaśākṣaramantra in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीमहात्रिपुरसुन्दरीमहाशक्तिराजराजेश्वरीषोडशाक्षरीमहामन्त्रस्य आनन्दभैरव ऋषिः, पङ्क्तिः छन्दः, श्रीमहात्रिपुरसुन्दरी महाशक्तिर्देवता ; ऐं क ए ई ल ह्रीं बीजं, सौः स क ल ह्रीं शक्तिः, क्लीं ह स क ह ल ह्रीं कीलकं, मम श्रीमहात्रिपुर . . . . . योगः ।

End:

मनुः—

श्रीं ह्रीं क्लीं ऐं सौः ओं श्रीं ह्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं सौः श्रीं ॥

No. 7454. षोडशाक्षरमन्त्रः.
ṢŌḌAŚĀKṢARAMANTRAḤ.

Pages, 2. Lines, 11 on a page.

Begins on fol. 16*a* of the MS. described under No. 547.

Complete.

Similar to the above.

Beginning:

अस्य श्रीषोडशाक्षरीमहात्रिपुरसुन्दरीमहामन्त्रस्य नित्यानन्दभैरव ऋषिः, तुरीयगायत्री छन्दः, श्रीषोडशाक्षरी श्रीविद्या देवता, श्रां बीजं, श्रीं शक्तिः, श्रूं कीलकं, श्रीविद्याश्रीमहात्रिपुरसुन्दरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं पुनर्न्यासः ॥

No. 7455. षोडशाक्षर्यादिमूलमन्त्रः.
ṢŌḌAŚĀKṢARYĀDIMŪLAMANTRAḤ

Page, 1. Lines, 10 on a page.

Begins on fol. 194*b* of the MS. described under No. 124.

Complete.

Contains the bare formulas representing the Ṣōḍaśākṣarī, Pañcadaśākṣarī, Annapūrṇā, Vāgīśvarī, Lakṣmyēkākṣarī, Kāmadhēnu, Kalyāṇagaurī, Rajaśyāmalā, Rājamātaṅgī and Śukaśyāmalā Mantras.

Beginning:

षोडशाक्षरी—

श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं सौः श्रीं ।

End:

शुकश्यामला—

ऐं नम उच्छिष्टचण्डालि मातङ्गि सर्ववशङ्करि स्वाहा ॥

No. 7456. संक्षोभिणीमन्त्रः.
SAṀKṢŌBHINĪMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 45*a* of the MS. described under No. 2886, wherein it is found in the Ākāśabhairavakalpa 38*a* in the list of other works.

Complete as found in the 50th Adhyāya of the Ākāśabhairavakalpa.

The repetition of this Mantra which is addressed to the goddess Saṁkṣōbhiṇī who is held to be a manifestation of Śakti is considered to have the power to enable one to cause bewilderment and confusion to one's enemies.

Beginning:

संक्षोभिण्याः अगस्त्यः, पङ्क्तिश्छन्दः, सर्वसंक्षोभिणी, षं बी, माया श, सर्वसंक्षोभणार्थे ।

End:

तस्करश्शत्रुपीडा च जन्तुभूतादिपूजि(पीडि)तम् ।
स्वप्नकालेवि(ऽपि) नैव स्या(त्) वरेण्यो नात्र संशयः ॥

Colophon:

इति आकाशभैरवकल्पे पञ्चाशोऽध्यायः ॥

No. 7457. संभोगमहादुर्गामन्त्रः.

SAMBHŌGAMAHĀDURGĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 47*b* of the MS. described under No. 5445

Complete.

The repetition of this Mantra which is addressed to Mahadurgā is considered to have the power to bring happiness to the worshipper.

Beginning:

अस्य श्रीसंभोगमहादुर्गामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, सम्भोगमहादुर्गा देवता, मम तत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मन्त्रस्तु—

ओं आं क्लीं क्रां क्लीं ... क्लीं क्रों क्लीं आं ओं, लक्षजपपुनश्चरणम। ओं ह्रां क्लीं भगमालिनि भगं मे देहि क्लीं ह्रीं ओं ।

जपं च लक्षं निशि चैव कार्यं समन्त्रसिद्धिस्स्वरसेन संभवेत् । ओं ह्रीं श्रां सौं क्रों ह्रीं स्वाहा ॥

रात्रौ मन्त्रसहस्रन्तु जपेदीशानदिङ्मुखः ॥

No. **7458.** संमोहनगोपालमन्त्रः.
SAMMŌHANAGŌPĀLAMANTRAH.

Pages, 2. Lines, 5 on a page

Begins on fol. 55b of the MS. described under No. 5885

Complete.

This Mantra is addressed to Kṛṣṇa conceived as a charming cowherd.

Beginning:

अस्य श्रीसंमोहनगोपालमन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, श्रीसंमोहनगोपालो देवता, आं बीजं, क्रों शक्तिः, ब्लूं कीलकं, श्रीसंमोहनगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

आं क्रों ब्लूं कृष्णाय रुक्मिणीवल्लभाय स्वाहा ॥

No. **7459.** संमोहनसुन्दरीमन्त्रः.
SAMMOHANASUNDARĪMANTRAH.

Pages, 2. Lines, 18 on a page.

Begins on fol. 278b of the MS. described under No. 5477, wherein it is found in the Mantramālikā 273a in the list of other works.

Complete.

The repetition of this Mantra, which is addressed to Saṁmōhanasundarī, is considered to have the power to enable one to bring all people under one's influence and control.

Beginning:

अस्य श्रीसंमोहनसुन्दरीमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, संमोहनसुन्दरी देवता ; ह्रीं बीजं, नमः शक्तिः, मम सर्वजनवश्यार्थे विनियोगः ।

End:

मन्त्रः—

ओं ह्रीं श्रीं सर्वजनमोहिनि ह्रीं नमस्स्वाहा ॥

Colophon:

इति संमोहनी ॥

No. 7460. संमोहनसुन्दरीमन्त्रः.

SAMMŌHANASUNDARĪMANTRAḤ.

Page, 1. Lines, 26 on a page.

Begins on fol. 236b of the MS. described under No. 581, wherein it is found in the Mantramālikā in the list of other works given therein.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसंमोहनसुन्दरीमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, संमोहनसुन्दरी देवता, ह्रीं बीजं, नमश्शक्तिः, मम सर्वजनवश्यार्थे विनियोगः ।

End:

मन्त्रः—

ह्रीं मुखकमलवासिनि ऐं क्लीं ह्रीं श्रीं सर्वजनसंमोहिनि ह्रीं नमः ॥

No. 7461. संमोहनसुन्दरीमन्त्रः.

SAMMŌHANASUNDARĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 90b of the MS. described under No. 5556

Complete.

Same as the above.

No. 7462. संवित्त्रिशूलिनीमन्त्रः.

SAMVITTRIŚŪLINĪMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 223a of the MS. described under No. 537.

Complete

The repetition of this Mantra, which is addressed to Amṛtasiddhēśvarī, who is considered to be a manifestation of Śakti and is probably the presiding deity of the intoxicating Indian hemp, is supposed to have the power to enable one to obtain happiness in this world and salvation after death.

Beginning:

अस्य श्रीसंवित्ति[नी]शूलिनीमन्त्रस्य आनन्दभैरव ऋषिः, अमृत-विराट् छन्दः, अमृतसिद्धेश्वरी देवता, ऐं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, भोगमोक्षार्थे जपे विनियोगः ।

End:

ऐं क ए ई ल ह्रीं क्लीं ह स क ह ल ह्रीं सौः स क ल ह्रीं । विश्वतैजसप्राज्ञपुरुषाय मनोवागार्जितं कर्म आत्मने ब्रह्मणे जुहोमीति । . .

अहमस्मि ब्रह्माहमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा । श्रीनाथादिगुरुत्रयं गुरोर्मण्डलम् ॥

* * * *

अळिपिशितपुरन्ध्रीभोगपूजारतोऽहं
बहुविधकुळमार्गद्रव्यसंभावितोऽहम् ।
पशुजनविमुखोऽहं भैरवीमाश्रितोऽहं
गुरुचरणरतोऽहं भैरवोऽहं शिवोऽहम् ॥

No. **7463.** संवित्परमेश्वरीमन्त्रः.

SAṀVITPARAMEŚVARĪMANTRAḤ.

Pages, 3. Lines, 14 on a page.

Begins on fol. 70*b* of the MS. described under No. 5673.

Complete.

Similar to the above.

Held to be efficacious in also defeating the aims of one's enemies.

Beginning:

अस्य श्रीसंवित्परमेश्वरीमन्त्रस्य आनन्दभैरव ऋषिः, अमृतविराट् छन्दः, श्रीसंवित्परमेश्वरी देवता ; ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, मम संवित्परमेश्वरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ऐं क्लीं सौः सर्वतत्त्वं महाकारणदेहं परिशोधयामि जुहोमि स्वाहा ।
भङ्गिभङ्गि महाभङ्गि भवभङ्गीविमोचनि ।
मम शत्रुमनोभङ्गं कुरु कुरु हुं फट् स्वाहा ॥

* * * *

मात्राभिर्दशषोडशस्वरयुतं ज्योतिर्विशुद्धात्मकं
हंक्षेत्यक्षरयुग्मपत्रकमलं मुक्ताभमाज्ञापुरम् ।
तस्मादूर्ध्वमुखं सदाशिवमयं पद्मं सहस्रच्छदं
नित्यानन्दमयं सदा शिवमयं हं सं सदा भावये ॥

No. 7464. संवित्सेवनामन्त्रः

SAṀVITSĒVANĀMANTRAḤ.

Pages Lines, 7 on a page.

Begins on fol. 11*a* of the MS. described under No. 673, wherein it is found in the Ṣaḍāmnāyamantra 1*a* in the list of other works.

Complete.

The use of the intoxicating Indian hemp followed by the repetition of this Mantra is considered to have the power to enable one to become inspired with the spiritual enlightenment needed for realizing the identity of one's self with the supreme Brahman.

Beginning:

अस्य श्रीसंवित्सेवनामन्त्रस्य आनन्दभैरव ऋषिः, अमृतविराट् छन्दः, कुरुकुल्लाशिनी महाभैरवी देवता ; ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, मम संवित्सेवने विनियोगः ।

End:

ऐं सिद्धमौलि सम्यग्भूतिं कुरु कुरु सम्य(संवि)द्रूपधारिणि मां बोधय बोधय स्वाहा । . . . .

अहमस्मि ब्रह्माहमस्मि ; अहमेवाहं मां जुहोमि स्वाहा—इति मन्त्रेण संवित्सेवनं कुर्यात् ।

No. 7465. संवित्सेवनामन्त्रः.

SAMVITSĒVANĀMANTRAH.

Pages, 2. Lines, 5 on a page.

Begins on fol. 144*a* of the MS. described under No. 673, wherein it is given as Samviddēvīmantra in the list of other works.

Complete.

Similar to the above

Beginning:

अस्य श्रीसंवित्सेवनामन्त्रस्य आनन्दभैरव ऋषिः, अमृतविराट् छन्दः, कुरुकुल्लाशिनी महाभैरवी देवता; ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, मम संवित्सेवने जपे विनियोगः ।

End:

ऐं सिद्धमौलिश्रिया देवि ज्ञानबोधप्रबोधनि । राजव्रजवशीकरिणि कालकण्ठि त्रिशूलिनि । ऐं सिद्धमौलि सम्यग्भूर्ति कुरु कुरु सम्यग्र(संविद्रू)-पधारिणि मां बोधय बोधय स्वाहा—इति त्रिवारं गुरून् सन्तर्प्य शेषं स्वीकृत्य (कुर्यात्) ॥

No. 7466. संविन्मन्त्रः.

SAMVINMANTRAH.

Pages, 3. Lines, 14 on a page.

Begins on fol. 257*a* of the MS. described under No. 424, wherein it is given as Samviccūlinīmantra in the list of other works.

Complete

This Mantra is addressed to the hemp plant which is itself held to represent the goddess Śūlinī.

Beginning:

अस्य श्रीसमिध्(संवि)न्महामन्त्रस्य आनन्दभैरव ऋषिः, समि(संवि)-च(त्स्व)रूपिणी शूलिनी देवता; ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, मम समिंदे(संविदे)विप्र -गः ।

End:

शत्रुक्षयं चक्रमुद्रां ज्ञानमुद्रात्मबोधिनीम् ।
सन्धानयोनिमुद्राश्च ऐश्वर्यं धेनुमुद्रयोः ॥

त्रेतायां शोणितप्रभोऽश्यावर्णकलयुगेमां(?) जुहोमि स्वाहा ॥ ऋषस्य चरमामृतम् ॥

No. **7467**. संहारभैरवमन्त्रः.
SAṀHĀRABHAIRAVAMANTRAḤ.

Pages, 2. Lines, 20 on a page.

Begins on fol. 1*a* of the MS. described under No. 2373.

Complete.

This Mantra is addressed to Bhairava as engaged in the act of destruction.

Beginning:

अस्य श्रीसंहारभैरवमहामन्त्रस्य विश्वामित्र ऋषिः, गार्यत्रा छन्दः, आदिनाथभैरवो देवता ; क्षां बीजं, क्षीं शक्तिः, क्षूं कीलकं, संहारभैरवप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं ह्रीं क्षं क्षेत्रपालाय नमः । लक्षजपेन सिद्धिर्भवति ॥

No. **7468**. संहारभैरवमन्त्रः.
SAṀHĀRABHAIRAVAMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 1*a* of the MS. described under No. 365.

Complete.

Same as the above

No. **7469**. सङ्गीतमातङ्गीमन्त्रः.
SAṄGĪTAMĀTAṄGĪMANTRAḤ.

Pages, 2. Lines, 14 on a page

Begins on fol. 13*a* of the MS. described under No. 5673, wherein it is found in Āmnāyamantramālikā 1*a* in tha list of other works.

Complete.

The repetition of this Mantra, which is addressed to Mātaṅgī, is considered to have the power to enable one to become well-versed in the art of music.

Beginning :

अस्य श्रीसङ्गीतमातङ्गीमहामन्त्रस्य नारदभगवान् ऋषिः, त्रिष्टुप् छन्दः, श्रीसङ्गीतमातङ्गी देवता ; ओं बीजं, स्वाहा शक्तिः, ओं कीलकं, मम सकलसङ्गीतविशारद(त्व)ार्थे श्रीसङ्गीतमातङ्गीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

ओं नमो भगवति विं वीणायै मम सङ्गीतविद्यां प्रबोधय प्रबोधय स्वाहा । श्रीसङ्गीतमातङ्गीश्री ॥

No. 7470. सङ्गीतविद्यामन्त्रः.
SAṄGĪTAVIDYĀMANTRAḤ.

Page, 1. Lines, 4 on a page.

Begins on fol. 29*a* of the MS. described under No. 2848, wherein it is found in the Āmnāyamantramālikā 16*a*. For Pūrvāmnāyamantramālikā 16*a* in the list of other works therein given, read Āmnāyamantramālika 16*a*.

Complete.

Similar to the above.

Beginning and **End :**

कामनानुगुणगानकल्पनाकल्पशिल्पतरुणीपुरस्सरा(म्) ।
वेणुकीस्तनतटीविहारिणीं वल्लकीं मनसि भावयाम्यहम् ॥
ऐं वीणायै मम सङ्गीतविद्यां प्रयच्छ स्वाहा ॥

No. 7471. सन्तानगोपालमन्त्रः.
SANTĀNAGŌPĀLAMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol 145*a* of the MS. described under No 673

Complete.

The Mantra described under No. 5970 is the same as that given here.

The preliminary details alone slightly differ.

Beginning:

अस्य श्रीसन्तानगोपालमन्त्रस्य दूर्वास ऋषिः, अनुष्टुप् छन्दः, मम पुत्रप्रदश्रीगोपालकृष्णो देवता, मम सुपुत्रावाप्त्यर्थे विनियोगः ।

End:

देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं देव त्वामहं शरणं गतः ॥
नित्यमष्टशतं जप्त्वा पुत्रप्राप्तिर्भविष्यति ।

No. **7472.** सन्तानगोपालमन्त्रः.
SANTĀNAGŌPĀLAMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 21*b* of the MS. described under No. 2886.

Complete.

The Mantra here given is the same as in the above; the preliminary details alone are somewhat different.

Beginning:

अस्य श्रीसन्तानगोपालमहामन्त्रस्य नारदो भगवानृषिः, अनुष्टुप् छन्दः, देवकीसुतेति बीजं, गोविन्देति शक्तिः, वासुदेवेति कीलकं, सन्तानगोपालप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥

No. 7473. सन्तानगोपालमन्त्रः.

SANTĀNAGŌPĀLAMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 39*a* of the MS. described under No. 3056.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसन्तानगोपालमहामन्त्रस्य नारदभगवानृषिः, अनुष्टुप् छन्दः, श्रीसन्तानगोपालश्रीकृष्णो देवता; क्लीं बीजं, स्वाहा शक्तिः, ओं कीलकं, सन्तानगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

मन्त्रः—

देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥

No. 7474. सन्तानगोपालमन्त्रः.

SANTĀNAGŌPĀLAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 52*b* of the MS. described under No. 5885, wherein it is given as Santānapradagōpālamantra.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसन्तानप्रदगोपालमन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, सन्तानप्रदगोपालो देवता, देवकीसुत गोविन्देति बीजं, वासुदेव जगत्पते इति शक्तिः, देहि मे तनयं कृष्ण इति कीलकं, सन्तानप्रदगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥

No. 7475. सन्तानगोपालमन्त्रः.
SANTĀNAGŌPĀLAMANTRAḤ.

Pages, 4. Lines, 5 on a page.

Begins on fol. 35*a* of the MS. described under No. 5818.

Complete.

Similar to the above.

How the various letters of this Mantra are to be inscribed on the consecrated metallic plate is mentioned at the end.

Beginning:

एवङ्गुणविशेषणविशिष्टा(यां)शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्यविजयायुरारोग्यैश्वर्याभिवृद्ध्यर्थं. . . . .
सत्सन्तानसौभाग्यसिद्ध्यर्थं सन्तानगोपालमहामन्त्रजपं करिष्ये —

अस्य श्रीसन्तानगोपालमहामन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, श्रीसन्तानगोपालकृष्णपरमात्मा देवता ; क्लीं बीजं, स्वाहा शक्तिः, श्रीं कीलकं, मम सन्तानगोपालप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं क्लीं ह्रीं श्रीं देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥

वसुदले मूलमन्त्रं चतुस्सङ्ख्यया लिखेत् । शिष्टमेकदले । भूपुरेषु अकरादिक्षकारान्तं लिखेत् । दिक्पालकबीजं भूपुरस्याष्टकोणे लिखेत् ॥

Colophon:

इति सन्तानगोपालयन्त्रः ॥

No. 7476. सन्तानगोपालमन्त्रः.
SANTĀNAGŌPĀLAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 16*b* of the MS. described under No. 2854, wherein it has been apparently omitted to be included in the list of other works given therein.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसन्तानगोपालमन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, श्रीसन्तानगोपालकृष्णो देवता, क्लीं बीजं, श्रीं शक्तिः, देवकीसुत इति कीलकं, सन्तानगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

ओं क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥

No. **7477.** सन्तानगोपालमन्त्रः.

SANTĀNAGŌPĀLAMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 43*a* of the MS. described under No. 5858.

Complete.

Similar to the above.

Herein the Mantra in praise of Nṛsiṁha, which is in the Anuṣṭup metre, is enjoined to be repeated after the repetition of the Santānagōpālamantra.

Beginning:

अस्य श्रीसन्तानगोपालमहामन्त्रस्य नारदभगवानृषिः, अनुष्टुप् छन्दः, परमात्मा श्रीसन्तानगोपालो देवता ; क्लीं बीजं गोविन्देति शक्तिः, वासुदेवेति कीलकं, मम पुत्रसन्तानार्थे जपे विनियोगः ।

End:

देहि मे तनयं कृष्ण त्वामहं शरणङ्गतः ॥ मनुः--

ओं क्लीं स्वाहा ॥

अनुष्टुप्मन्त्रराजस्य(जान्ते) नारसिंहं स्मरेत्ततः ।
उग्रवीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ॥

नृसिंहं भीषणं भद्रं मृत्युं मृत्योर्नमाम्यहम् ॥
त्रिकालं जपतां सन्तानसिद्धिः॥

Colophon:

इति सन्तानगोपालमन्त्रः ॥

No. **7478.** सन्ध्यामन्त्रः.
SANDHYĀMANTRAḤ.

Pages, 32. Lines, 5 on a page.

Begins on fol. 1*a* of the MS. described under No. 5660.

Complete.

This is the daily prayer to be offered by the followers of the Yajurvēda three times a day, viz., in the morning, at noon and in the evening.

Beginning:

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यस्स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः ॥

केशवाय स्वाहा, नारायणाय स्वाहा, माधवाय स्वाहा । गोविन्दाय नमः, विष्णवे नमः, मधुसूदनाय नमः, त्रिविक्रमाय नमः । . . . .

पृथिव्या मेरुपृष्ठ ऋषिः, कूर्मो देवता, सुतलं छन्दः, आसने विनियोगः । प्रणवस्य परब्रह्म ऋषिः, परमात्मा देवता, देवी गायत्री छन्दः, प्राणायामे विनियोगः ।

End:

सर्वा ता विष्य शिथिरेव देवा अथा ते स्याम वरुण प्रियासः । ओं नमः प्रतीच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमः ॥

Colophon:

इति त्रिकालसन्ध्या समाप्ता ॥

No. **7479.** सन्ध्यामन्त्रः.

SANDHYĀMANTRAḤ.

Pages, 8. Lines, 6 on a page.

Begins on fol. 64*a* of the MS. described under No. 5660.

Incomplete.

Similar to the above. This form of the prayer is intended for Śaivas.

Beginning:

पृथिव्या मेरोः पृष्ठ ऋषिः, कूर्मो देवता, सुतलं छन्दः, आसने विनियोगः ।

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यस्स्मरेत् गिरिजाधीशं स बाह्याभ्यन्तरश्शुचिः ॥

केशव, नारायण, माधव, गोविन्द, विष्णु, मधुसूदन, त्रिविक्रम, वामन, श्रीधर, हृषीकेश, पद्मनाभ, दामोदर, सङ्कर्षण, वासुदेव, प्रद्युम्न, अनिरुद्ध ।

End:

पूतं पवित्रेणैवाज्यम् । आपश्शुन्धन्तु मैनसः । ओं भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्.

No. **7480.** सन्ध्यामन्त्रः.

SANDHYĀMANTRAḤ.

Pages, 6. Lines, 6 on a page.

Begins on fol. 83*a* of the MS. described under No. 217, wherein it is given as Sandhyākramaḥ in the list of other works.

Incomplete.

Same as the above.

No. **7481.** सन्ध्यावन्दनमन्त्रः.

SANDHYĀVANDANAMANTRAḤ.

Pages, 2. Lines, 19 on a page.

Begins on fol. 27*b* of the MS. described under No. 2886.

Complete.

This prayer is generally offered by the Śāktas Instead of Vēḍic passages they use Dēvīmantras in their prayers ; hence it is called Tantra-sandhyāvandana.

Beginning:

अस्य श्रीसन्ध्यावन्दनमन्त्रस्य सान्दीपिनिभगवान् ऋषिः, अनुष्टुप् छन्दः, सन्ध्या देवता; शोभनवक्र(वर्ण)मिति बीजं, नीलग्रीवायेति शक्तिः, वरदाभयहस्तान्तामिति कीलकं, समस्तपापक्षयार्थे वन्दने विनियोगः ।

End:

प्रातस्सन्ध्ये परानन्दे परब्रह्मात्मिके शिवे ।
वन्दे त्वां च महाबाले गायत्री पाहि मां सदा ॥

Colophon:

इति वन्दनविधिः ॥

No. **7482.** सन्ध्यावन्दनमन्त्रः.

SANDHYĀVANDANAMANTRAḤ.

Pages, 2. Lines, 19 on a page.

Begins on fol. 32*a* of the MS. described under No. 2886.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसन्ध्यावन्दनमन्त्रस्य सान्दीपिनिभगवानृषिः, अनुष्टुप् छन्दः, ब्रह्मा देवता; शोभनवर्णं कीलकं, नीलग्रीवायेति शक्तिः, मोक्षार्थे जपे विनियोगः ।

End:

पाहि पाहि महादेवि पातकादुपपानकात् ।
अपिकर्ता पिपासाच्च पाहि पाहीति मां सदा ॥

Colophon:

इति विश्वामित्रकल्पे ॥

No. **7483.** सरस्वतीदेवीमन्त्रः.

SARASVATĪDĒVĪMANTRAḤ.

Page, 1. Lines, 9 on a page.

Begins on fol. 3*b* of the MS. described under No. 6548, wherein it is given as Sarasvatimantra in the list of other works.

Complete.

This Mantra is addressed to the goddess Sarasvatī; and its repetition is considered to have the power to enable one to become a learned person and a poet.

Beginning:

अस्य श्रीसरस्वतीदेवीमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीसरस्वती देवी देवता; सं बीजं, स्वाहा शक्तिः, श्रीसरस्वतीदेवीप्रसादसिद्ध्यर्थे सारस्वतार्थे सर्वबोधनार्थे च विनियोगः ।

End:

नवनलिननिरूढा वल्लभा पद्मजस्य द्युतिविहसितचन्द्रोद्दामकान्तिः प्रसन्ना ।
विहरतु मम चित्ते सर्वबोधप्रदात्री वितरतु च कवित्वं सर्वलोकप्रसिद्धम् ॥

मन्त्रः—

ओं सं सरस्वति स्वाहा ॥

No. **7484.** सरस्वतीमन्त्रः.

SARASVATĪMANTRAḤ.

Page, 1. Lines, 17 on a page.

Begins on fol. 102*b* of the MS. described under No. 5568.

Complete.

This Mantra is also addressed to Sarasvatī; and its repetition is considered to have the power to enable one to bring people under one's control and influence.

Beginning and **End**:

पुस्तकजपपटहस्ते वरदाभयचिह्नचारुबाहुलते ।
कर्पूरामलदेहे वागीश्वरि शोधयतु(याशु) मम चेतः ॥

ओं नमो भगवति वागीश्वरि सकलराजवशीकरणि सत्त्व(र्व)स्त्रीपुरुष-
वशीकरणि क्लीं ह्रीं श्रीं स्वाहा ॥

No. 7485. सर्वकामदेवमनोहरामन्त्रः.

SARVAKĀMADĒVAMANŌHARĀMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 252*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* in the list of other works.

Complete.

The repetition of this Mantra, which is addressed to a certain goddess named Sarvakāmadēvamanōharā, (one who bestows all desires and is charmingly beautiful even to the gods) is considered to have the power to enable one to obtain wealth, which must however be spent away if one wants to retain the favour of the goddess.

Beginning and **End**:

मन्त्रः—

ओं ह्रीं सर्वकाम(दे)देवमनोहरे स्वाहा ।
नदीतीरे शुभे देशे चन्दनेन सुमण्डलम् ॥
विधाय पूजयेद्देवीं ततो मन्त्रायुतं जपेत् ।
त्रिसप्ताहं जपेदेवं प्रसन्ना वितरेत्सदा ॥
दीनाराणां सहस्रैकं व्ययं कुर्याद्दिने दिने ।
विना व्ययेन सा क्रुद्धा न ददाति कदाचन ॥

No. **7486.** सर्वकामदेवमनोहरामन्त्रः.

SĀRVAKĀMADĒVAMANŌHARĀMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 99*a* of the MS. described under No. 5566, wherein it has been omitted to be included in the list of other works.

Complete.

Same as the above.

No. **7487.** सर्वकामदेवमनोहरामन्त्रः.

SARVAKĀMADĒVAMANŌHARĀMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 298*b* of the MS. described under No. 5477, wherein it is found in the Mantramālikā 273 in the list of other works.

Complete.

Similar to the above.

Beginning:

ओं ह्रीं सर्वकाम(दे)देवमनोहरे स्वाहा ।

End:

वीणारामां (दीनाराणां) सहस्रैकं व्ययं कुर्याद्दिने दिने ।
विना व्ययेन सा क्रुद्धा न ददाति कदाचन ॥

No. **7488.** सर्वजनवशीकरणमन्त्रः.

SARVAJANAVAŚĪKARAṆAMANTRAḤ.

Page, 1. Lines, 22 on a page.

Begins on fol. 14*a* of the MS. described under No. 6045, wherein it has been apparently omitted to be included in the list of other works.

Complete.

This Mantra is addressed to Lakṣmī, probably conceived as a manifestation of Śakti; and its repetition is considered to be efficacious in bringing people under one's control and influence.

Beginning:

ओं ऐं श्रीं ह्रीङ्कारि महालक्ष्मि मौक्तिकालङ्कारिणि परमानन्दमानसे सर्वमोहनवशीकरणि ।

End:

मम श्रीं प्रवेशय प्रवेशय मम प्रभुवश्यं कुरु कुरु स्वाहा ॥

No. **7489.** सान्दीपिपुत्रप्रदगोपालमन्त्रः.

SĀNDĪPIPUTRAPRADAGŌPĀLAMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 49*b* of the MS. describel under No. 5885.

Complete.

This Mantra is intended to propitiate Kṛṣṇa as he restord back to the sage Sāndīpi his son who had got drowned in the ocean.

Beginning:

अस्य श्रीसान्दीपिपुत्रप्रदगोपालमन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, श्रीसान्दीपिपुत्रप्रदायकगोपालो देवता, आं बीजं, श्रीं शक्तिः, क्रों कीलकं, सान्दीपिपुत्रप्रदायकगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

आं श्रीं क्रों कृष्णाय देवकीगर्भसंभूताय ह्रीं वं स्वाहा ॥

No. **7490.** साम्बदक्षिणामूर्तिमन्त्रः.

SĀMBADAKṢIṆĀMŪRTIMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 135*b* of the MS. described under No. 537.

Complete.

This Mantra is intendel to propitiate Dakṣiṇāmūrti as associated with Ambā.

Beginning:

अस्य श्रीसाम्बदक्षिणामूर्तिमहामन्त्रस्य आनन्दवामदेव ऋषिः, अमृतविराट् छन्दः, श्रीसाम्बदक्षिणामूर्तिर्देवता; ओं ऐं बीजं, नमः क्लीं

शक्तिः, शिवाय सौः कीलकं, श्रीसाम्बदक्षिणामूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

पञ्चोपचारैस्संपूज्य, ओं ऐं नमः क्रीं शिवाय सौः ॥

No. 7491. साम्बदक्षिणामूर्तिमन्त्रः.

SĀMBADAKṢIṆĀMŪRTIMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 309*a* of the MS. described under No. 5477, wherein it is found in the Mantramālikā 273 in the list of other works.

Complete.

Similar to the above.

Beginning :

अस्य श्रीसाम्बदक्षिणामूर्तिमन्त्रस्य आनन्दवामदेव ऋषिः, भोगपङ्क्तिश्छन्दः, शिवाय सौः कीलकं, साम्बदक्षिणामूर्तिप्रीत्यर्थे जपे विनियोगः ।

End :

ओं ऐं नमः क्रीं शिवाय सौः । पुनश्चरणं लक्षम् । दशांशं होमः । इति ॥

No. 7492. साम्बदक्षिणामूर्तिमन्त्रः.

SĀMBADAKṢIṆĀMŪRTIMANTRAḤ.

Page, 1. Lines, 11 on a page.

Begins on fol. 252*b* of the MS. described under No. 424.

Complete.

Similar to the above.

Beginning :

अस्य श्रीसाम्बदक्षिणामूर्तिमहामन्त्रस्य आनन्दवामदेव ऋषिः, पङ्क्तिश्छन्दः, श्रीसाम्बदक्षिणामूर्तिर्देवता ; ओं ऐं बीजं, नमः शक्तिः,

शिवाय सौः कीलकं, श्रीसाम्बदक्षिणामूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

ध्यानम्—

वामोरोरुपरि स्थितां गिरिसुतामन्योऽन्यमालिङ्गितां
श्यामामुत्पलधारिणीं शशिनिभं चालोकयन्तीं शिवम् ।
आश्लिष्टेन करेण पुस्तकमथो कुम्भं सुधापूरितं
मुद्रां ज्ञानमयीं दधानमपरां मुक्ताक्षमालां भजे ॥

मनुः ॥

No. **7493.** साम्बदक्षिणामूर्तिमन्त्रः.

SĀMBADAKṢIṆĀMŪRTIMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 23*a* of the MS. described under No. 5928.

Complete.

Similar to the above.

Beginning :

अस्य श्रीसाम्बदक्षिणामूर्तिमहामन्त्रस्य शुक ऋषिः, विराट् छन्दः, साम्बदक्षिणामूर्तिः परमात्मा देवता; जीवं बीजं, क्लीं नमश्शक्तिः, शिवाय सौः कीलकं, श्रीदक्षिणामूर्तिप्रीत्यर्थे जपे विनियोगः ।

End :

ओं ऐं क्लीं सौः नमश्शिवाय पञ्चपूजां कुर्यात् । श्रीसाम्बदक्षिणामूर्तेः पादुकां पूजयामि ॥

No. **7494.** सारस्वतप्रदगोपालमन्त्रः.

SĀRASVATAPRADAGŌPĀLAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 53*a* of the MS. described under No. 5885.

Complete.

This Mantra is considered to have the power to please Kṛṣṇa conceived as the bestower of learning and knowledge.

Beginning:

अस्य श्रीसारस्वतप्रदगोपालमन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, सारस्वतप्रदगोपालो देवता, ऐं बीजं, स्वाहा शक्तिः, ओं कीलकं, सारस्वतप्रदगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ॥

No. **7495.** सालग्राममन्त्रः.

SĀLAGRĀMAMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 33*a* of the MS. described under No. 292.

Complete.

The repetition of this Mantra is considered to have the power to secure the favour of Rāma conceived as residing in Sālagrāmas and thereby to enable one to accomplish one's desires and to remove all difficulties and troubles

Beginning:

अस्य श्रीसालग्राममन्त्रस्य श्रीवेदव्यासभगवान् ऋषिः, अनुष्टुप् छन्दः, सालग्रामवासिश्रीरामो देवता; ओं बीजं, स्वाहा शक्तिः, सालग्रामवासिश्रीरामप्रीत्यर्थे जपे विनियोगः ।

End:

ओं नमो भगवते विष्णवे सालग्रामनिवासिने सर्वाभीष्टफलप्रदाय सकलदुरितनिवारिणे सालग्रामाय स्वाहा ॥

No. **7496.** सावित्राष्टाक्षरमन्त्रः.

SĀVITRĀṢṬĀKṢARAMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 64*b* of the MS. described under No. 5885, wherein it is given as Sāvitrāṣṭākṣarī.

Complete.

This Mantra consisting of 8 syllables is addressed to the Sun-god; and its repetition is considered to be efficacious in the curing of various kinds of diseases, in the accomplishment of one's desires and in the attainment of salvation.

Beginning:

पूर्वोक्तएवंगुणविशेषणविशिष्टायां शुभतिथौ मम सकलपापक्षयार्थमैकाहिकद्व्याहिकत्र्याहिकचातुराहिकादिसकलरोगशान्त्यर्थं समस्तमङ्गलावाप्त्यर्थं सावित्राष्टाक्षरीमन्त्रजपं करिष्ये—अस्य श्रीसावित्राष्टाक्षरीमन्त्रस्य भार्गव ऋषिः, गायत्री छन्दः, आदित्यो देवता; कं बीजं, यं शक्तिः, दं कीलकं, मम इष्टार्थसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं श्रीं ह्रीं क्लीं घृणिस्सूर्य आदित्यों ।

शुद्धात्मा रविजश्श्रीमान् तस्माद्रोगाद्विमुक्तवान् ।
अष्टाविंशतिकुष्ठानि महारोगाणि यानि च ॥
अशीतिवातरोगाश्च प्रणश्यन्ति न संशयः ।
कुर्वन्नेवंप्रकारेण भुक्तिं मुक्तिं च विन्दति ॥

No. **7497.** सावित्रीपञ्जरम्.

SĀVITRĪPAÑJARAM.

Pages, 2. Lines, 19 on a page.

Begins on fol. 31*a* of the MS. described under No. 2886.

Complete as found in the 45th Adhyāya of the Vāsiṣṭha-saṁhitā.

The repetition of this Mantra which is addressed to the goddess Sāvitrī is considered to have the power to secure protection to one and to enable one to accomplish whatsoever one may desire.

Beginning:

सावित्रीपञ्जरं नाम रहस्यं निगमत्रये ।
ऋष्यादिकञ्च दिग्वर्णसाङ्गावरणसंक्रमात् ॥
वाहनायुधमन्त्रास्त्रमूर्तिध्यानपुरस्सरम् ।
स्तोत्रञ्च ते प्रवक्ष्यामि त्वयि स्नेहाच्च नारद ॥
ब्रह्मनिष्ठाय देयं स्यान्न देयं यस्य कस्यचित् ।
आचम्य नियतः पश्चादात्मध्यानपुरस्सरम् ॥
* * * *
त्रिपदा ऋङ्मयी पूर्वमुखी ब्रह्मास्त्रसंज्ञिता ।
चतुर्विंशतितत्त्वाढ्या पातु प्राचीं दिशं मम ॥

End:

किमत्र बहुनोक्तेन शृणु नारद तत्त्वतः ।
यं यं काममभिध्यायन् तं तमाप्नोत्यसंशयः ॥

Colophon:

इति श्रीवासिष्ठसंहितायां वसिष्ठपराशरसंवादे सावित्रीपञ्जरं नाम पञ्चचत्वारिंशोऽध्यायः ॥

No. **7498.** साहित्यमातङ्गीमन्त्रः.

SĀHITYAMĀTAṄGĪMANTRAḤ.

Pages, 2. Lines, 14 on a page.

Begins on fol. 13*b* of the MS. described under No. 5673, wherein it is found in the Āmnāyamantramālikā 1*a* in the list of other works.

Complete.

Similar to the work described under No. 7289.

Beginning:

अस्य श्रीसाहित्यमातङ्गीमहामन्त्रस्य कृष्ण ऋषिः, गायत्री छन्दः, श्रीसाहित्यमातङ्गी देवता; ओं बीजं, स्वाहा शक्तिः, व्यं कीलकं, मम साहित्यविद्याप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—

ऐं ह्रीं श्रीं ओं नमो भगवते व्यं वेणवे मम साहित्यविद्यां प्रयच्छ स्वाहा । श्रीसाहित्यमातङ्गीश्री ।

*　　*　　*　　*

इति पूर्वाम्नायदेवताश्च मूलाधारे महच्चिक्रे च पूजयेत् ॥

No. **7499.** साहित्यविद्यामन्त्रः.

SĀHITYAVIDYĀMANTRAḤ.

Page, 1. Lines, 4 on a page

Begins on fol. 29*a* of the MS. described under No. 2848, wherein it is found in the Āmnāyamantramālikā in the list of other works For Pūrvāmnāyamantramālikā 16*a* read Āmnāyamantramālikā 16*a* in the list of other works.

Wants a portion in the beginning.

Similar to the above.

Beginning and **End**:

वक्रसौरभवशीकृतरन्ध्रो वस्तुना पटुतरावयवेन ।
गानदोहनकलाकलनादो मानदो भवतु मे मणिवेणुः ॥

ओं नमो भगवते वें वेणवे मम साहित्यविद्यां प्रयच्छ स्वाहा । साहित्यविद्यादेव्यम्बाश्री ॥

No. **7500.** सिद्धगणपतिमन्त्रः.

SIDDHAGAṆAPATIMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 15*a* of the MS. described under No. 5639.

Complete.

The repetition of this Mantra is considered to have the power to propitiate Siddhagaṇapati, being a special manifestation of Vināyaka.

Beginning :

अस्य श्रीसिद्धगणपतिमहामन्त्रस्य वामदेव ऋषिः, निचृद्गायत्री छन्दः, महागणपतिर्देवता; ग्लां बीजं, ह्रीं शक्तिः, ग्लूं कीलकं, मम सिद्धगणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

ओं नमो गजाननाय ओं नमः स्वाहा ॥

No. **7501.** सिद्धगणपतिमालामन्त्रः.

SIDDHAGAṆAPATIMĀLĀMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 15*a* of the MS. described under No. 5639, wherein it has been omitted to be given in the list of other works.

Complete.

Similar to the above.

The transcription of this manuscript is said to have been completed on the 2nd day of the dark fortnight of the month of Pusya in the year Viśvāvasu by Allamudi Bāpirāju, and the transcript handed over to Kurnella Veṅkaṭarāmaśāstrin.

Beginning and **End:**

मालामन्त्रः—

ओं ह्रीं श्रीं ह्रीं ग्लौं गं गणपतये नमः वरद वरद सर्वजनं मे वशमानय स्वाहा ॥

No. **7502.** सिद्धौघानन्दमन्त्रः.

SIDDHAUGHĀNANDAMANTRAḤ.

Pages, 2. Lines, 14 on a page.

Begins on fol. 3*b* of the MS. described under No. 5673, wherein it is found in the Āmnāyamantramālikā *la* given therein in the list of other works.

Complete.

The repetition of this Mantra is considered to have the power to propitiate the assemblage of nine Śāktagurus known as Siddhas.

Beginning:

अस्य श्रीसिद्धौघानन्दमन्त्रस्य सिद्धौघानन्दभैरव ऋषिः, अव्यक्तं छन्दः, श्रीसिद्धौघो देवता; आं बीजं, ओं शक्तिः, ई कीलकं, मम सिद्धौघानन्दप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

करालिकाम्बासिद्धश्री ४, भीविण्डाम्बासिद्धश्री ४, भीमाम्बासिद्धश्री ४, खराल्यम्बासिद्धश्री ४, खराननाम्बासिद्धश्री ४ विधिशालिन्यम्बासिद्धश्रीपादुकाम् ॥

No. **7503.** सिद्धौघानन्दमन्त्रः.

SIDDHAUGHĀNANDAMANTRAḤ.

Pages, 3. Lines, 4 on a page.

Begins on fol. 19*b* of the MS. described under No. 2848, wherein it is found in the Āmnāyamantramālikā 16*a* in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसिद्धौघानन्दमन्त्रस्य आनन्दभैरव ऋषिः, अव्यक्तगायत्री छन्दः, श्रीसिद्धौघो देवता; आं बीजं, ओं शक्तिः, ई कीलकं, मम श्रीनवसिद्धप्रसादसिद्ध्यर्थे विनियोगः ।

End:

मनुः—

ह्रीं श्रीं सौः आं महादुर्मरणसिद्धश्रीपादुकां . . . . . .
. . . . . . विधिशालिन्यम्बासिद्धश्री॥

No. 7504. सिद्धमूलिनीमन्त्रः.
SIDDHAMŪLINĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 228*a* of the MS. described under No. 124, wherein it has been omitted to be included in the list of other works.

Complete.

This Mantra is enjoined to be repeated at the time of taking gañja (hemp) as an aid to the practice of Yōga.

Beginning:

अस्य श्रीसिद्धमूलिनीमहामन्त्रस्य सिद्धानन्दभैरव ऋषिः, अनुष्टुप् छन्दः, सिद्धमूलिनी देवता; ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, मम सिद्धमूलिनीप्रसादद्वारा संवित्सेवने विनियोगः ।

End:

श्रीपरमेष्ठिगुरवे चिदाभासानन्दनाथश्री ह स क्ष म ल व र य ऊं स ह क्ष म ल व र य ईं आनन्दभैरवाय वौषट् । ललाटान्त-मुद्धृत्य अर्धं ज्वलतीति जुहुयात् । श्रीं अपसर्पन्तु—शिवाज्ञया ॥

No. 7505. सिद्धलक्ष्मीयक्षिणीमन्त्रः.
SIDDHALAKṢMĪYAKṢINĪMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 251*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* in the list of other works.

Complete.

This Mantra is addressed to the Siddhalakṣmīyakṣiṇī, and its repetition is considered to have the power to enable one to accomplish one's desires.

Beginning and End:

ऐं कमले कमलधारिणि हं स स्वाहा । स्वगृहे रक्तकरवीरपुष्प-पूजान्तरे लक्षजपं कुर्यात् । गुग्गुलत्तुकेन दशांशहोमं कुर्यात् ।

ददाति सङ्गमं तस्य तेन चिन्तितरूपिणी ।
चिन्तितार्थं तदा तस्य नात्र कार्या विचारणा ॥

No. 7506 सिद्धलक्ष्मीयक्षिणीमन्त्रः.
SIDDHALAKṢMĪYAKṢIṆĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 99*a* of the MS. described under No. 5566, wherein it has been omitted to be included in the list of other works.

Complete.

Same as the above.

No. 7507. सिद्धविद्यामन्त्रः.
SIDDHAVIDYĀMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 230*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā in the list of other works.

Complete.

The repetition of this Mantra is considered to have the power to make even celestial damsels fall in love with the person repeating it duly.

Beginning:

अस्य श्रीसिद्धविद्यामन्त्रस्य इन्द्र ऋषिः, महाविराट् छन्दः, सिद्धलक्ष्मीर्देवता; श्रीं बीजं, शकारश्शक्तिः, श्रीसिद्धलक्ष्मीप्रीत्यर्थे विनियोगः ।

End:

प्रणतजनवत्सले देवि महाकालि कालनाशनि हूं हूं हूं प्रसीद मदनातुरां आं क्रों कुरु कुरु सुरासुरकन्यकां ह्रीं श्रीं (हुं फट् स्वाहा) ॥ ह्रीं नमः श्रीं नमः । चत्वारिंशत्पुरश्चरणं कुर्यात् । दशांशतर्पणहोमः ॥

No. 7508. सिद्धविद्यामन्त्रः.
SIDDHAVIDYĀMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 86*b* of the MS. described under No. 5566.

Complete.

Same as the above.

No. 7509. सीतराममन्त्रः.
SĪTĀRĀMAMANTRAḤ.

Pages, 2. Lines, 14 on a page.

Begins on fol. 46*b* of the MS. described under No. 567., wherein it is found in the Āmnāyamantramālikā 1*a* in the list of other works.

Complete.

The repetition of this Mantra is considered to have the power to secure for one the favour of Rāma as associated with Sītā.

Beginning:

अस्य श्रीसीतारामंमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीसीतारामो देवता; रां बीजं, ओं श्रीं शक्तिः, रामायेति कीलकं, मम श्रीसीतारामप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं श्रीं रां रामाय नमः ॥

No. 7510. सुदर्शनकवचः.
SUDARŚANAKAVACAḤ.

Pages, 10. Lines, 6 on a page.

Begins on fol. 227*a* of the MS. described under No. 7247.

Complete as found in the Vihagendrasaṁhitā.

This Kavacamantra is addressed to Viṣṇu's 'discus' conceived as a deity; and its repetition is considered to be efficacious in securing protection to one and in causing the accomplishment of one's desires.

Beginning:

अस्य श्रीसुदर्शनकवचसौत्य(स्तोत्र)महामन्त्रस्य अहिर्बुध्न्यभगवानृषिः, अनुष्टुप् छन्दः, श्रीमान् महासुदर्शनो देवता; सं सहस्रार इति बीजं, हुं महासुदर्शनेति शक्तिः, फट् चक्राडिति कीलकं, सुदर्शनकवचमहामन्त्रमूर्तेः मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

* * * *

मस्तकं मे सहस्रारः फालं पातु सुदर्शनः ।
भ्रुवौ मे चक्रराट् पातु नेत्रे ज्ञ(मे)ऽर्केन्दुलोचनः ॥

End:

बहुनात्र किमुक्तेन यद्यद्वाञ्छति मानवः ।
सकलं प्राप्नुयात्तस्य कवचस्य प्रसादतः ॥

Colophon:

इति विहगेन्द्रसंहितायां तार्क्ष्यनारायणसंवादे अगस्त्यप्रोक्तं सुदर्शनकवचं सम्पूर्णम् ॥

No. 7511. सुदर्शनकवचः.

SUDARŚANAKAVACAḤ.

Pages, 4. Lines, 21 on a page.

Begins on fol. 15*a* of the MS. described under No. 2373, wherein it is given as Sudarśanakavacastōtra in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसुदर्शनकवचस्तोत्रमन्त्रस्य अन्तर्यामिनारायण ऋषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनपरमात्मा देवता; सहस्रार इति बीजं, सुदर्शन इति शक्तिः, चक्राडिति कीलकं, श्रीमहासुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोगः ।

* * * *

मस्तकं मे सहस्रारः पातु फालं सुदर्शनः ।
भ्रुवौ मे चक्रराट् पातु नेत्रेऽग्न्यर्केन्दुलोचन. ॥

End:

इति सौदर्शनं दिव्यं कवचं सर्वकामदम् ।
क्षिप्रं सुदर्शनं चक्रं ज्वालामालाविभूषितम् ॥

* * * *

ऊरुस्तम्भं हनुस्तम्भं निमिषं ज्वल गर्दभाक् ।
तीक्ष्णधार महावेग छिन्धि छिन्धि न वेदनात्(?) ॥

No. **7512.** सुदर्शनकवचः.
SUDARŚANAKAVACAḤ.

Pages, 4. Lines, 8 on a page.

Begins on fol. 14*a* of the MS. described under No. 6090.

Complete.

Same as the above.

No. **7513.** सुदर्शनकवचः.
SUDARŚANAKAVACAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 12*b* of the MS. described under No. 365, wherein it is given as Sudarśanamantra in the list of other works.

Complete.

Same as the above.

No. **7514.** सुदर्शनकवचः.
SUDARŚANAKAVACAḤ.

Pages, 4. Lines, 6 on a page.

Begins on fol. 1*b* of the MS. described under No. 5338, wherein it has been omitted to be given in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसुदर्शन(कवच)स्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीसुदर्शनरूपी महाविष्णुर्देवता, सुदर्शनप्री(त्यर्थे) जपे विनियोगः ।

* * * *

शिरो मे भगवान्देवो रक्षतु श्रीसुदर्शनः ।
फालदेशं चक्रदेवः कालनेमिहरो भ्रुवौ ॥

End:

षट्कोणान्तरमध्यपद्मनिलयं तत्सन्धिदिष्टाननं
चक्राद्यायुधचारुभूषणभुजं सज्वालकेशोदयम् ।
वस्त्रालेपनमाल्यविग्रहतनुं तं फालनेत्रं गुणैः
प्रत्यालीढपदाम्बुजं त्रिनयनं चक्राधिराजं भजे ॥

No. **7515.** सुदर्शनकवचः.
SUDARŚANAKAVACAḤ

Page, 1. Lines, 19 on a page.

Begins on fol. 4*a* of the MS. described under No. 2886, wherein it has been omitted to be given in the list of other works.

Complete.

Similar to the above.

Beginning:

(अस्य श्रीसुदर्शनकवचस्तोत्र)मन्त्रस्य अहिर्बुध्न्यभगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनरूपी महाविष्णुर्देवता ; रां बीजं, स्वाहा शक्तिः, फट् कीलकं, श्रीसुदर्शनप्रीत्यर्थे जपे विनियोगः ।

शिरो मे भगवान् देवो रक्षतु श्रीसुदर्शनः ।
फालदेशं च चक्रेशः कालनेमिहरो भ्रुवौ ॥

End:

नानालोकेषु त्रैलोक्ये नानाशैलवनेषु च ।
नानानदीतटाकेषु जपतां भक्तवत्सलः ॥

* * * *

सुदर्शनचक्राय ज्वालाचक्राय महाचक्राय स्वाहा ॥

Colophon:

सुदर्शन(कवच)मन्त्रः समाप्तः ॥

No. 7516. सुदर्शनकवचः.
SUDARŚANAKAVACAḤ.

Pages, 6. Lines, 5 on a page.

Begins on fol. 5a of the MS. described under No. 6393.

Complete.

The repetition of this Mantra is considered to have the power to destroy all evil-doing agencies and to secure protection to one.

Beginning:

अस्य श्रीसुदर्शनकवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, सुदर्शनमहाचक्रो देवता, मम सर्वरक्षक(णा)र्थे जपे विनियोगः ।
सुदर्शनजपं करिष्ये—अथ न्यासः ।

सुदर्शनमहाचक्रो गोविन्दस्य करायुधः ।
तीक्ष्णधात(रो)महावेगः सूर्यकोटिसमप्रभः ॥

त्रैलोक्यरक्षाकर्तृत्वं(त्वात्) दुष्टराक्षसभञ्जन[म्] । ओं सहस्रार हुं फट् स्वाहा ।

End:

राक्षसासुरबेतालपिशाचोरगपाक्षिणः । छिन्धि छिन्धि सर्वभयं चैव ।

* * * *

ज्वालाखेलत्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्याये षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥

No. 7517. सुदर्शनकवचः.
SUDARŚANAKAVACAḤ.

Substance, palm-leaf. Size, $16\frac{1}{8} \times 1\frac{3}{8}$ inches. Pages, 3. Lines, 6 on a page. Character, Grantha. Condition, slightly injured. Appearance, old.

Begins on fol. 18a. The other works herein are Sudarśanaśataka 1a, Lakṣmīstōtra 15a, Sudarśanaprapatti 17a, Sudarśanayantrapūjā 20a, Sudarśanamālāmantra 20a, Ṣōḍaśāyudhastōtra 21a, Sudarśanāṣṭaka 23a.

Complete.

Similar to the above.

Beginning:

सिंहासने समासीनं देवेन्द्रं त्रिदशेश्वरम् ।
श्रोतुं चक्रस्य कवचं सुधर्मामगमन् सुराः ॥
देवदेव सहस्राक्ष दैत्यान्तक शचीपते ।
त्वत्तस्सौदर्शनीं विद्यां श्रोतुका(माशा)स्महे वयम् ॥

इन्द्र उवाच—

पुरा भगवतश्श्रीमदहिर्बुध्न्यान्मया श्रुतम् ।
दिव्यं सत् कवचं वक्ष्ये शृणुध्वं सुरसत्तमाः ॥

* * * *

शिरो मे भगवान् देवो रक्षतु श्रीसुदर्शनः ।
फालदेशं तु चक्रेशः कालनेमिहरो भ्रुवौ ॥

End:

इतीदं कवचं दिव्यं सर्वकामफलप्रदम् ।
सर्वपापप्रशमनं महाभयनिवारणम् ॥

Colophon:

इति श्रीसुदर्शनकवचं संपूर्णम् ॥

No. **7518.** सुदर्शनकवचः.

SUDARŚANAKAVACAḤ

Substance, palm-leaf. Size, 16 × 1¾ inches. Pages, 2 Lines, 8 on a page. Character, Grantha. Condition, injured. Appearance, old.

Begins on fol. 15*a*. The other works herein are Sudarśanaśataka 1*a*, Sudarśanadigbandhanamantra 12*a*, Sudarśanasaḍaksarīmantra 14*a*, Sudarśanamālāmantra 14*b*. Sudarśanaprapatti 16*a*, Vihagēndrasaṁhitā 17*a*.

Complete.

Similar to the above.

Beginning:

सिंहासने समासीनं देवेन्द्रं त्रिदशेश्वरम् ।
श्रोतुं चक्रस्य कवचं सुधर्मामगमन् सुराः ॥

* * * *

दिव्यमाल्याम्बरधरं भूषणैरुपशोभितम् ।
ध्यात्वैवं चक्रकवचं जपेत्सर्वार्थसिद्धये ॥
शिरो मे भगवान् देवो रक्षतु श्रीसुदर्शनः ।
फालदेशं च चक्रेशः कालनेमिनिबर्हणः ।

End:

इतीदं कवचं दिव्यं सर्वकामफलप्रदम् ।
सर्वपापप्रशमनं महाभयनिवारणम् ॥

Colophon:

इति सुदर्शनकवचं सम्पूर्णम् ॥

No. **7519.** सुदर्शनकवचः.

SUDARŚANAKAVACAḤ.

Pages, 1. Lines, 5 on a page.

Begins on fol. 13*a* of the MS. described under No. 5938.

Complete.

Similar to the above

Beginning:

अस्य श्रीसुदर्शनकवचस्तोत्रमन्त्रस्य अहिर्बुध्न्यो भगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनरूपी श्रीमहाविष्णुर्देवता ।

शिरो मे भगवान् देवो रक्षतु श्रीसुदर्शनः ।
फालदेशं च चक्रेशः कालनेमिहरो भ्रुवौ ॥

End:

षट्कोणान्तरतारमध्यनिलयं संस्फीतदंष्ट्राननं
चक्राद्यायुधचारुषोडशभुजं सज्वालकेशोज्ज्वलम् ।
वस्त्रालेपनमाल्यविग्रहगुणैस्तं बालमित्रारुणैः
प्रत्यालीढपदाम्बुजं त्रिनयनं चक्राधिराजं भजे ॥

No. 7520. सुदर्शनकवचः.

SUDARŚANAKAVACAḤ.

Pages, 13. Lines, 6 on a page.

Begins on fol. 30*a* of the MS. described under No. 5864.

Complete as found in the Vihagēndrasaṁhitā.

Similar to the above.

Beginning:

अस्य श्रीसुदर्शनकवचस्तोत्रमहामन्त्रस्य अहिर्बुध्न्यभगवान् ऋषिः, गायत्री छन्दः, श्रीमान् महासुदर्शनो देवता; सं सहस्रार इति बीजं हुं महासुदर्शनेति शक्तिः, फट् चक्राडिति कीलकं, सुदर्शनकवचमहामन्त्रमूर्तेः मम सर्वाभीष्टप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

यन्त्रे च मन्त्रकवचं पठित्वा सर्वकामधृत् ॥
बहुनात्र किमुक्तेन यद्यद्वाञ्छति मानवः ।
सकलं प्राप्नुयात्तस्य कवचस्य प्रसादतः ॥

Colophon:

इति श्रीविहगेन्द्रसंहितायां तार्क्ष्यनारायणसंवादे अगस्त्यप्रोक्तं सुदर्शनकवचं संपूर्णम् ॥

No. 7521. सुदर्शनगायत्री.

SUDARŚANAGĀYATRĪ.

Page, 1. Lines, 19 on a page.

Begins on fol. 3*b* of the MS. described under No. 2886, wherein the general name Sudarasanamantra is given in the list of other works.

This Mantra which is addressed to Viṣṇu's 'discus' is in the form of the Gāyatrīmantra, and hence it is called Sudarśanagāyatrī.

Beginning and **End:**

सुदर्शनाय विद्महे(हे)तिराजाय धीमहि । तन्नश्चक्रः प्रचोदयात् ॥

Colophon:

इति गायत्री ॥

No. 7522. सुदर्शनदिग्बन्धनमन्त्रः.

SUDARŚANADIGBANDHANAMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 3*b* of the MS. described under No. 2886, wherein the general name Sudarśanamantra is given in the list of other works.

Complete.

The repetition of this Mantra which is addressed to Viṣṇu's 'discus' is considered to have the power to protect one from the dangers that may possibly come from the various quarters.

Beginning:

ऐन्द्रीं दिशं चक्रेण बध्नामि, आग्नेयीं दिशं चक्रेण बध्नामि, याम्यां दिशं चक्रेण बध्नामि ।

End:

ऊर्ध्वां दिशं चक्रेण बध्नामि, अधरां दिशं चक्रेण बध्नामि, ज्वालाचक्राय नमः ॥

Colophon:

इति दिग्बन्धः ॥

No. 7523. सुदर्शनदिग्बन्धनमन्त्रः.

SUDARŚANADIGBANDHANAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 14*a* of the MS. described under No. 6180.

Incomplete.

Similar to the above.

Beginning and **End:**

ऐन्द्र्यां दिशि चक्रेण बध्नामि ओं नमश्चक्रराजाय हुं फट् सुदर्शनायामर्षणाय स्वाहा । याम्य - वारुण - कुबेर - ईशान्य - अग्नि - नैरृत्य - वायव्य - ऊर्ध्व - अधर.

No. 7524. सुदर्शनदिग्बन्धनमन्त्रः.

SUDARŚANADIGBANDHANAMANTRAḤ.

Pages, 8. Lines, 6 on a page.

Begins on fol. 5*a* of the MS. described under No. 5822, wherein it is found in the Sudarśanamūlamantra 1*a* in the list of other works.

Complete.

Similar to the above.

Beginning:

अथ दिग्बन्धनमन्त्रः —

ओं नमो भगवते महोग्रदिग्बन्धनसुदर्शनाय अष्टादशबाहुप्रचण्डदश-दिग्बन्धनाय ।

End:

ऐं ज्वालाचक्राय अधःपातालाय दिग्बन्धनाय स्वाहा । ओं दीप्त-चक्राय ऊर्ध्वप्रदेशदिग्बन्धनाय स्वाहा । भूर्भुवस्सुवरों—इति दिग्बन्धः ॥

ध्यानम्—

शङ्खं चक्रं च चापं . . . . सकलरिपुजनप्राणसंहार-चक्रम् ॥

No. 7525. सुदर्शनदिग्बन्धनमन्त्रः.

SUDARŚANADIGBANDHANAMANTRAḤ.

Pages, 4. Lines, 7 on a page.

Begins on fol. 12*a* of the MS. described under No. 7518.

Complete.

Similar to the above.

Beginning:

अथ वक्ष्यामि सौवीरं दिग्बन्धविधिमुत्तमम् ।

इन्द्रादिदशदिक्षु च . . यो मे पुरस्तात् पूर्वभागं गतः पाप्मा वा पापकेनेह कर्मणा इन्द्रस्स देवो राजा जम्भयत्वित्यादि . स्वाहा ।

जम्भयतु स्तम्भयतु जृम्भयतु मोहयतु मारयतु नाशयतु क्लेशयतु शोषयतु कलिं तस्मै प्रयच्छतु कृतं मम शुभं, मम शिवं, मम शान्तिः, मम स्वस्त्ययनं, मम हुं फट् सुदर्शनाय स्वाहा ।

End:

उत्तरस्यां दिशायां महाभीमको नाम श्रीभूतः तस्याष्टकोटिश्रीभूतगणेन दिशं बन्धयामि ॥

Colophon:

इति सुदर्शनदिग्बन्धनविधिस्समाप्तः ॥

श्रीसुदर्शनपुरुषः सुप्रीतो वरदो भूत्वा त्रैलोक्यं रक्ष मां रक्ष । ओं नमो भगवते सुदर्शनाय ज्वालाचक्राय सहस्रार हुं फट् । श्रीसुदर्शनपुरुषाय शत्रुमर्षणाय वीरमायाय नमः ऐन्द्रीं दिशं चक्रेण बन्धयामि एवमेव सर्वा दिशश्च बन्धयामि ॥

No. 7526. सुदर्शनपूर्वोत्तरमालामन्त्रः.

SUDARŚANAPŪRVŌTTARAMĀLĀMANTRAH

Pages, 1 Lines, 8 on a page.

Begins on fol. 1*a* of the MS. described under No. 6090, wherein it is given as Sudarśanamantra 1*a* in the list of other works.

Complete.

The repetition of this Mantra is considered to have the power to propitiate Viṣṇu's 'discus' and to destroy everything which can possibly injure the supplicant, besides securing protection to him

Beginning:

शङ्खं चक्रं च चापं . . . . . प्राणसंहारचक्रम् ॥

* * *

ओं नमो भगवते महासुदर्शनाय महाचक्राय महाज्वालाय महादीप्तरूपाय सर्वतो रक्ष रक्ष महाबलाय स्वाहा हूं फट् स्वाहा ।

अस्य श्रीसुदर्शनमहामन्त्रस्य अहिर्बुध्न्यभगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनरूपी श्रीमहाविष्णुर्देवता; रं बीजं, हुं शक्तिः, स्वाहा कीलकं, मम श्रीसुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

परमन्त्रान् ग्रासय ग्रासय भक्षय भक्षय त्रासय त्रासय परयन्त्रं निवारय निवारय वृश्चिकभल्लूकस्फोटकादीन् नाशय नाशय सर्वं दह दह भस्म भस्म कुरु कुरु चक्रनारायणमहाविष्णवे नमो रक्ष रक्ष हुं फट् स्वाहा ॥

No. 7527. सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 23*b* of the MS. described under No 124.

Complete.

The repetition of this Mantra is considered to have the power to enable one to accomplish everything which one may desire.

Beginning:

अस्य श्रीसुदर्शनमन्त्रस्य अहिर्बुध्न्यभगवानृषिः, सुदर्शनो देवता, सं बीजं, हं शक्तिः, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

End:

शङ्खं चक्रं सचापं परशुमसिक(व)रं शूलपाशाङ्कुशाग्रं
बिभ्राणं वज्रपीठं(खेटं) हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलमुखं हारकेयूरभूषं
ध्याये षट्कोणचक्रं सकलरिपुहरं(जन) प्राणसंहारचक्रम् ॥
ओं सहस्रार हुं फट् ॥

No. 7528. सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 37*b* of the MS. described under No. 3056.

Complete.

Similar to the above.

Beginning :

अस्य श्रीसुदर्शनषडक्षरमहामन्त्रस्य अहिर्बुध्न्यो भगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनो देवता; रं बीजं, हुं शक्तिः, फट् कीलकं, श्रीसुदर्शनप्रीत्यर्थे जपे विनियोगः ।

See under the previous number for the end.

No. 7529. सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ.

Pages, 2. Lines, 9 on a page.

Begins on fol. 1?*b* of the MS. described under No. 6090.

Complete.

Similar to the above.

Beginning :

एवंगुणविशेषणविशिष्टायामस्यां शुभतिथौ अस्माकं सकुटुम्बानां फलसिद्ध्यर्थं श्रीसुदर्शनदेवतामुद्दिश्य श्रीसुदर्शनदेवताप्रीत्यर्थं सुदर्शन-स्तोत्रमन्त्रपठनं करिष्ये—

अस्य श्रीसुदर्शनस्तोत्रमहामन्त्रस्य अहिर्बुध्न्यो भगवानृषिः, श्री-सुदर्शनः परमात्मा देवता; रं बीजं, हुं शक्तिः, फट् कीलकं, मम श्री-सुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

लमिति पञ्चपूजां कुर्यात् । मुद्रां प्रदर्श्य, मनुः—
ओं सहस्रार हुं फट् । पुनः न्यासं कुर्यात् ।

* * * *

भगवन् सर्वविजयी सहस्रारापराजित ।
शरणं त्वां प्रपन्नोऽस्मि श्रीकरश्रीसुदर्शन ॥

No. 7530. सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 325*b* of the MS. described under No. 5477 wherein it is found in the Mantramālikā 273*a* in the list of other works.

Complete.
Similar to the above.

Beginning:

अस्य श्रीसुदर्शनमन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, सुदर्शनमहाविष्णुर्देवता ; हुं बीजं, स्वाहा शक्तिः, मम इष्टकाम्यार्थसिद्ध्यर्थे विनियोगः ।

End:

ओं ह्रीं सहस्रार हुं फट् । इति ॥

No. **7531.** सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 64*a* of the MS. described under No. 5885 wherein it is given under the name of Sudarśanaṣaḍakṣarīmantra in the list of other works.

Complete.
Similar to the above.

Beginning:

अस्य श्रीसुदर्शनषडक्षरीमहामन्त्रस्य अहिर्बुध्न्य ऋषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनरूपी विष्णुर्देवता, सं बीजं, हुं शक्तिः, श्रीसुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—

ओं सहस्रार हुं फट् ॥

No. **7532.** सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 14*a* of the MS. described under No. 5864

Complete.
Similar to the above.

Beginning :

अस्य श्रीसुदर्शनमन्त्रस्य अहिर्बुध्न्यभगवान् ऋषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनो देवता ; रं बीजं, हुं शक्तिः, फट् कीलकं, श्रीसुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

मनुः—
ओं सहस्रार हुं फट् ॥

No. **7533.** सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ.

Page, 1. Lines, 21 on a page.

Begins on fol. 17*a* of the MS. described under No. 2373, wherein it has been omitted to be included in the list of other works.

Complete.

Considered also to be efficacious in the destruction of one's enemies.

Beginning :

ओं ह्रीं ह्रीं ह्रीं ह्रीं ह्रूं ह्रूं फट्कारेण ठः ठः द्वयेन हन हन द्विषः
हा हा हू हू हुवित्येव फट्कारेण हन द्विषः ।
सुदर्शनस्य मन्त्रेण ग्रहा यान्ति दिशो दश ॥

End :

ह्राः ह्राः ह्रां ह्रां ह्रां हा हा हू हू हं फट् हन हन द्विषः । स्वाहा ॥

No. **7534.** सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 13*b* of the MS. described under No. 365, wherein it has been omitted to be included in the list of other works.

Complete.

Same as the above.

No. 7535. सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ

Page, 1. Lines, 8 on a page.

Begins on fol 15b of the MS. described under No 6090, wherein it has been omitted to be included in the list of other works.

Complete

Same as the above.

No. 7536. सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ.

Substance, palm-leaf Size, $10\frac{3}{4} \times 1\frac{1}{4}$ inches. Pages, 3. Lines, 9 on a page. Character, Grantha. Condition, injured. Appearance, new.

Begins on fol. 11*a*. The other works herein are Bhajayatirājastōtra 1*a*, Bhajagōvindastōtra 4*a*, Śukastōtra 7*a*, Bhīṣmastuti 8*a*, Saptaślōkarāmāyaṇa 9*a*, Karṇāmṛta 12*a*, Dvādaśanāmastōtra 13*b*.

Incomplete

Similar to the above.

Beginning:

देवी गायत्री छन्दः, प्राणायामे विनियोगः ।

त्रिः प्राणानायम्य, सङ्कल्प्य; एवंगुणविशेषणाविशिष्टायामस्यां शुभातिथौ श्रीभगवदाज्ञया श्रीभगवत्प्रीत्यर्थं श्रीसुदर्शनमन्त्रजपं करिष्ये ।

अस्य श्रीसुदर्शनमहामन्त्रस्य श्रीवेदव्यास ऋषिः, श्रीमन्नारायणो देवता, सुदर्शनजपे विनियोगः ।

End:

शङ्खं चक्रं च चापं परशुमसिमिषुं शूलपाशाङ्कुशास्त्रं
बिभ्राणं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्याये षट्कोणसंस्थं (सकलरिपुजनप्राणसंहारचक्रम्) ॥

No. **7537.** सुदर्शनमन्त्रः.
SUDARŚANAMANTRAḤ.

Pages, 4. Lines, 8 on a page.

Begins on fol. 1*a* of the MS. described under No. 2838.

Complete.

Similar to the above.

The repetition of this Mantra is considered to have the power to safeguard and make effective the repetition of all Mantras

Beginning:

अस्य श्रीसुदर्शनमन्त्रस्य अहिर्बुध्न्य ऋषिः, अनुष्टुप् छन्दः, सुदर्शनो देवता ; रं बीजं, हुं शक्तिः, मम सकलमन्त्रानुष्ठानसंरक्षणार्थं सुदर्शनचक्रेण दश दिशो बन्धा(न्धया)मि । प्राणायामत्रयं कृत्वा ।

End:

हं क्षं हं क्षं हं क्षं हं क्षं श्रां क्रों आं क्रा आं क्रों आं क्रों ओं कालचक्राय स्वाहा, ज्रं नमः फट् हं नमः फट् फट् फट् कालचक्राय स्वाहा ॥

No. **7538.** सुदर्शनमन्त्रः.
SUDARŚANAMANTRAḤ.

Pages, 5. Lines, 6 on a page.

Begins on fol. 7*a* of the MS. described under No. 5819.

Complete.

Considered to have the power to drive off evil spirits.

Beginning:

अस्य श्रीसुदर्शनमन्त्रस्य अहिर्बुध्न्य ऋषिः, अनुष्टुप् छन्दः, सुदर्शनरूपी श्रीमहाविष्णुर्देवता ; स्रां बीजं, हुं शक्तिः, सुदर्शनप्रीत्यर्थे विनियोगः ।

End:

भूतान् निवारय निवारय त्रासय त्रासय हुं फट् स्वाहा ॥

No. 7539. सुदर्शनमन्त्रः.
SUDARŚANAMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 303*a* of the MS. described under No. 5477, wherein it is found in the Mantramālikā 73*a* in the list of other works.

Complete.

Similar to the above.

The Sudarśanamantras consisting of eight syllables and sixteen syllables are given here.

Beginning:

अस्य श्रीसुदर्शनमन्त्रस्य अहिर्बुध्न्य ऋषिः, अनुष्टुप् छन्दः, ओं बीजं, हुं फट् शक्तिः, सुदर्शनरूपी अहिर्देवता, सुदर्शनप्रीत्यर्थे विनियोगः ।

End:

ओं सहस्रार हुं फट् । द्वादशलक्षपुनश्चरणम् ।
आज्येन दशांशहोमः । तर्पणं द्वादशसहस्रम् ।
मन्त्रः—
ओं नमस्सुदर्शनाय —इत्यष्टाक्षरी । ओं नमो भगवते महासुदर्शनाय हुं फट्—इति षोडशाक्षरी ॥ ओं नमो भगवते नरसिंहाय वज्रकवचाय हिरण्याक्षवक्षोविदारणाय स्वाहा ॥

No. 7540. सुदर्शनमन्त्रः.
SUDARŚANAMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 243*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 23*a* in the list of other works.

Complete.

Similar to the above.

The Sudarśanamantras containing eight and sixteen syllables and the Sudarśanagāyatrīmantra are found herein.

Beginning:

अस्य श्रीसुदर्शनमन्त्रस्य आहिर्बुध्न्य ऋषिः, अनुष्टुप् छन्दः, ओं बीजं, हुं फट् शक्तिः, श्रीसुदर्शनचक्ररूपी हरिर्देवता, सुदर्शनप्रीत्यर्थे विनियोगः ।

End:

ओं सहस्रार हुं फट् । पुरश्चरणम् १२ लक्षम् । द्वादशसहस्रं होमः सर्षपतिलैः घृतपायसमिश्रबिल्वफलैः । द्वादशसहस्रं तर्पणम् ।

ओं नमस्सुदर्शनाय—इत्यष्टाक्षरी । ओं नमो भगवते महासुदर्शनाय हुं फट्—इति षोडशाक्षरी । सुदर्शनाय विद्महे महाज्वालाय धीमहि । तन्नश्चक्रः प्रचोदयात्—इति गायत्री ॥

No. 7541. सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 94*a* of the MS. described under No. 5566, wherein it has been wrongly stated to begin on fol. 98.

Complete.

Same as the above.

No. 7542. सुदर्शनमन्त्रः.

SUDARŚANAMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 5*a* of the MS. described under No. 5680.

Complete.

This contains the Sudarśanagāyatrīmantra, the ordinary Sudarśanamantra, the Sudarśanamantra containing sixteen syllables and the Sudarśanamālāmantra.

Beginning:

अस्य श्रीसुदर्शनमहामन्त्रस्य अहिर्बुध्न्यभगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनमहाविष्णुर्देवता ; रं बीजं, हुं शक्तिः, फट् कीलकं, इष्टार्थे विनियोगः।

End:

सुदर्शनाय विद्महे महाज्वालाय धीमहि । तन्नश्चक्रः प्रचोदयात्—इति गायत्री । ओं सहस्रार हु फट्—इति मन्त्रः । ओं नमो भगवते महासुदर्शनाय हुं फट्—इति षोडशाक्षरमन्त्रः । ओं नमो नमो भगवते वासुदेवाय . . . . . सर्वतो रक्ष रक्ष मां महाबलाय स्वाहा—इति मालामन्त्रः ॥

No. **7543.** सुदर्शनमन्त्रः—गायत्रीमालामन्त्रसहितः.

SUDARŚANAMANTRAḤ WITH GĀYATRI AND MĀLĀMANTRA.

Pages, 2. Lines, 6 on a page.

Begins on fol. 1*a* of the MS. described under No. 5338.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसुदर्शनमन्त्रस्य अहिर्बुध्न्य ऋषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनो देवता ; ओं बीजं, स्वाहा शक्तिः, रं कीलकं, श्रीसुदर्शनप्रीत्यर्थे जपे विनियोगः ।

End:

मनुः—

ओं ह्रीं श्रीं सहस्रार हुं (फट्) । सुदर्शनगायत्री—
सुदर्शनाय विद्महे महाज्वालाय धीमहि । तन्नश्चक्रः प्रचोदयात् ।
मालामनुः—

ओं नमो भगवते महासुदर्शनाय महाज्वालाय महाचक्राय दीप्तरूपाय सर्वतो मां रक्ष रक्ष महाबलाय स्वाहा ॥

No. 7544. सुदर्शनमालामन्त्रः.
SUDARŚANAMĀLĀMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 325*a* of the MS. described under No. 5477, wherein it is found in the Mantramālikā 273*a* in the list of other works.

Complete.

This Mantra is in praise of Sudarśana, or Viṣṇu's 'discus' under different significant names; and its repetition is considered to have the power to enable one to destroy one's enemies.

Beginning:

ओं नमो भगवते नन्दनाय सहस्रशीर्षाय क्षीरोदार्णवन्तय(शायि)-ने शेषभोगपर्यङ्काय गरुडवाहनाय नमः ।

End:

ओं नमो भगवते महासुदर्शनाय महाचक्राय जय जय रक्ष रक्ष मम शत्रून् नाशय नाशय ।

* * * *

विष्णुकवचस्थानां मन्त्राणां साहस्रज्वाला(य)
हुं मृत्युमृत्युं नाशय नाशय हुं फट् स्वाहा ॥

No. 7545. सुदर्शनमालामन्त्रः.
SUDARŚANAMĀLĀMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 14*b* of the MS. described under No. 5864, wherein it has been omitted to be shown as a separate work in the list of other works.

Complete.

Similar to the above.

Beginning:

मालामन्त्रः—

ओं नमो भगवते महासुदर्शन महाचक्रराज मां रक्ष रक्ष मम शत्रून् नाशयं नाशय घर घर धारय धारय ज्वल ज्वल प्रज्वल प्रज्वल ज्वालय ज्वालय ।

End:

आवेशयावेशय आकर्षयाकर्षय खण्ड खण्ड विषक(ह)रकवचह(म)-नुस्मरन् ओं सहस्रार हुं फट् स्वाहा ॥

No. **7546.** सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Pages, 6. Lines, 7 on a page.

Begins on fol. 1*a* of the MS. described under No. 5915, wherein it has been given as Sudarśanamantra in the list of other works.

Complete.

Similar to the above.

Beginning:

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् ।
दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥

सकारस्य वेद ऋषिः, अनुष्टुप् छन्दः, मरुर्देवता । हकारस्य वेद ऋषिः, विराट् छन्दः, हुताशनो देवता । स्राकारस्य वेद ऋषिः, अनुष्टुप् छन्दः, इन्द्राग्नी देवता ।

* * * *

ओं नमो भगवते महासुदर्शनाय महाचक्राय महाज्वालाय दीप्त-रूपाय ।

End :

भूर्भुवस्सुवरों—इति दिग्बन्धः । ध्यानम्—
शङ्खं चक्रं च चापं परशुमसिमिषुं शूलपाशाङ्कुशाब्जं
बिभ्राणं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्यायेत् षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥

No. 7547. सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Page, 2. Lines, 6 on a page.

Begins on fol. 212*a* of the MS. described under No. 7247.

Complete.

The repetition of this Mantra is intended to propitiate Viṣṇu and to secure protection to one from all dangers.

Beginning :

अस्य श्रीसुदर्शन(माला)महामन्त्रस्य अहिर्बुध्न्य ऋषिः, अनुष्टुप् छन्दः, सुदर्शनमहाविष्णुर्देवता, अं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, सुदर्शन-महाविष्णुप्रीत्यर्थे जपे विनियोगः ।

End :

सहस्राक्षाय सहस्रपादानुलोचनाय साहस्रकाय स्रां चर हुं चर फट् ज्वर मां रक्ष रक्ष सौम्य संपूर्णचक्राय हुं फट् फट् स्वाहा ॥

Colophon :

सुदर्शन(माला)चक्रं संपूर्णम् ॥

No. 7548. सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Pages, 2. Lines, 21 on a page.

Begins on fol. 17*a* of the MS. described under No. 2373, wherein it has been omitted to be included in the list of other works.

Complete.

The repetition of this Mantra is intended to kill the evil spirit which is tormenting one and to remove one's chronic diseases.

Beginning:

ओं रं क्षां सहस्रार ज्वालामालापरिवर्तिने मम देहस्थितममुकं ग्रहं हन हन आवर्तनरोगान् नाशय नाशय ।

End:

ओं नमो भगवते महासुदर्शनाय महाबडबानलाय विद्वेषिसंहारणाय हुं फट् स्वाहा । ओं नमो भगवते महासुदर्शनाय हुं फट् ॥

Colophon:

इति मूल(माला)मन्त्रः ॥

No. 7549. सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 14*a* of the MS. described under No. 365, wherein it has been omitted to be included in the list of other works.

Complete.

Same as the above.

No. 7550. सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Pages, 3. Lines, 8 on a page.

Begins on fol. 15*b* of the MS. described under No. 6090, wherein it has been omitted to be included in the list of other works.

Complete.

Same as the above.

No. 7551. सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 29b of the MS. described under No. **5864**, wherein it has been given as Sudarśanamantrōccāṭana in the list of other works

Complete.

The repetition of this Mantra, which is addressed to Viṣṇu's 'discus', is considered to have the power to enable one to drive away and destroy enemies and evil spirits, to remove one's sins, to make one healthy, etc.

Beginning:

ओं नमो भगवते भो भोः सुदर्शन दुष्टान् दारय दारय दुरितं हन हन पापं मथय मथय अमुकयजमाननियोगेन रोगान् दह दह अमुकयजमानस्य आरोग्यं कुरु कुरु फं स्फं ह्रां ह्रां ह्रीं ह्रीं ह्रुं ह्रुं ठः ठः सर्वदुष्टग्रहान् छिन्धि छिन्धि हा हा हा हा हा हा हुं हुं फट् फट् ।

End:

परमन्त्रपरयन्त्रपरतन्त्रौषधकृत्रिमादि दह दह भस्मीकुरु कुरु मम शत्रून् उच्चाटय उच्चाटय मारय मारय हुं फट् हुं फट् ॥

Colophon:

उच्चाटनं समाप्तम् ॥

No. 7552. सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 31b of the MS. described under No. 5737.

Complete.

Similar to the above.

Beginning:

ओं नमो भगवते महासुदर्शनाय महाचक्रराजाय रक्ष रक्ष मां, मम शत्रून् नाशय नाशय धर धर धारय धारय भिन्धि भिन्धि ज्वल ज्वल ज्वालय ज्वालय ।

End:

मोटय मोटय भञ्ज भञ्ज आवेशय आवेशय खड्ग खड्ग विष्णु-मनस्तरां शङ्ख चक्रं चापं हुं फट् स्वाहा ॥

No. **7553.** सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 9*a* of the MS. described under No. 5819, wherein it has been omitted to be shown as a separate work in the list of other works.

Complete.

Similar to the above.

Beginning:

ओं नमो भगवते सुदर्शनमहाचक्रराजाय दीप्तरूपाय सर्वतो मां रक्ष रक्ष महाज्वालाय स्वाहा ।

End:

ओं नमो भगवते भो भोस्सुदर्शनचक्र दुष्टं ताडय ताडय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु द्विषो हन हन आज्ञापय जनार्दन ओं हा हा हू हू हुं हुं फट् फट् ठ ठ ठः हन हन द्विष द्विष स्वाहा ॥

No. **7554.** सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 8*a* of the MS. described under No. 5680, wherein it has been omitted to be shown as a separate work in the list of other works and is included in Sudarśanamantra 5*a*.

Complete.
Similar to the above.

Beginning :

अस्य श्रीसुदर्शन(माला)मन्त्रस्य सङ्कर्षणभगवानृषिः, अनुष्टुप् छन्दः, सुदर्शनविष्णुर्देवता; सां बीजं, फट्शक्तिः, सूं कीलकं, सुदर्शनविष्णुप्रीत्यर्थे जपे विनियोगः ।

End :

मम शत्रून् नाशय नाशय मारय मारय छिन्धि छिन्धि शतसहस्रकोटि प्रज्वल शिखायै वौषट् । मां प्रेक्षय धारण दुष्टग्रहदहनान्तक हन हन पच पच कम्पय कम्पय खजं शतशिखायै वौषट् ॥

No. **7555.** सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ

Pages, 4. Lines, 6 on a page.

Begins on fol. 237*a* of the MS. described under No. 7247.

Complete.

Similar to the above. Also considered to have the power to enable one to counteract the evil effects of hostile Mantras and Tantras.

Beginning :

सुदर्शनचक्रराजमन्त्रराजाय ओं छिन्धि छिन्धि विदारय विदारय ओं शुस्से खन्वे (?) परमन्त्रपरयन्त्रपरतन्त्रच्छेदन परभूतप्रेतनाशं ओं फट् फट् स्वाहा । ओं सुदर्शनचक्रराजाय वि(पङ्क्ता)न्तदुष्टभयङ्कर छिन्धि छिन्धि छिन्धि विदारय परमन्त्रपरयन्त्रपरतन्त्रान् ग्रासय ग्रासय भक्ष भक्ष.

End :

ओं नमो भगवते सकलपरिधिप्रहरणाय सकलपातकतुषारकिरणाय काशीक्षेत्रनिबर्हणाय बाणासुरबाहुवनदवाग्नये अतिपरिमितदिव्यास्त्रतेजउत्पाटनाय कल्पान्तदहनाय महाविष्णवे शङ्खचक्रगदाधराय लक्ष्मीसमेताय अघनाशनकर्त्रे सर्वलोकशरण्याय क्षां क्ष्रूं हन हन हुं फट् स्वाहा ॥

No. **7556.** सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Pages, 8. Lines, 6 on a page.

Begins on fol. 36*b* of the MS. described under No. 5864.

Complete.

Similar to the above

Beginning:

ओं श्रीं ह्रीं क्लीं ऐं सुदर्शनमहावज्रराज देवदेव जय जयानन्तानन्ताप्रतिहताय (अ)नपाय(ा)नपाय विकट विकट वीर उग्र उग्र चण्ड चण्ड भीषण भीषण भैरव ।

End:

कल्पान्ताग्निप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं
रक्ताक्षं पिङ्गकेशं वरमकुटधरं भीमदंष्ट्राट्टहासम् ।
शङ्खं चक्रं गदाब्जे हलमुसलयुतं चापबाणाङ्कुशाखं
बिभ्राणं दोर्भिरीड्यं मनसि मुररिपुं भावयेच्चक्रसंस्थम् ॥

No. **7557.** सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 15*a* of the MS. described under No. 6180.

Complete.

The repetition of this Mantra is considered to have the power to secure protection to one from all dangers.

Beginning and **End**:

ओं नमो भगवते महासुदर्शनाय महाचक्राय महाज्वालाय महादीप्तरूपाय सर्वतो रक्ष रक्ष मां महाज्वालाय स्वाहा । आसाम (अवसाने) मन्त्राणामात्मनः प्रादक्षिण्यक्रमेण त्रिवारं रक्षां कुर्यात् ॥

No. 7558. सुदर्शनमालामन्त्रः.
SUDARŚANAMĀLĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 30*a* of the MS. described under No. 5832, wherein it is given as Sudarśanamantra in the list of other works.

Complete.

Similar to the above.

Beginning and **End:**

ओं नमो भगवते महासुदर्शनाय महाचक्ररूपाय सर्वत्र मां रक्ष रक्ष हुं फट् ठ ठ स्वाहा ॥

No. 7559. सुदर्शनमालामन्त्रः.
SUDARŚANAMAĹĀMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 234*a* of the MS. described under No. 7247.

Complete.

Similar to the above Held to have the power to enable one to drive away and destroy enemies and evil spirits.

Beginning:

ओं नमो ब्रह्मसुदर्शन चक्रराज सर्वदुष्टभयङ्कर भूतप्रेतपिशाचब्रह्म-राक्षसशाकिनीडाकिनीयक्षगन्धर्ववेताळादिग्रहान् छिन्धि छिन्धि ।

End:

सर्वशत्रून् उच्चाटय उच्चाटय मारय मारय हुं फट् स्वाहा ॥

No. 7560. सुदर्शनमालामन्त्रः.
SUDARŚANAMĀLMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 14*b* of the MS. described under No. 7518.

Complete.

Similar to the above.

Beginning:

ओं श्रीं ह्रीं क्लीं ऐं श्रीसुदर्शन महाचक्रराज देवदेव जय जय विजय विजय अपराजित अपराजित अप्रतिहत वीर वीर ज्वल ज्वल दह दह पच पच सर्वदुष्टभयङ्कर सर्वज्वरनिवारण सर्वज्वरविनाशन छिन्धि छिन्धि भिन्धि भिन्धि भञ्ज भञ्ज।

End:

त्रिभुवनदावाग्नये कल्पान्तदहनाय श्रीमहाविष्णवे ओं क्ष्रौं हन हन हुं फट् स्वाहा ॥

Colophon:

इति सुदर्शनमालामन्त्रः ॥

No. 7561. सुदर्शनमालामन्त्रः.
SUDARŚANAMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 8*b* of the MS. described under No. 5822, wherein it has been omitted to be shown as a separate work in the list of other works.

Complete.

Similar to the above. There are two leaves in the end written on in Tamil containing details regarding the conduct of the worship relating to this Mantra.

Beginning:

ओं नमो भगवते श्रीसुदर्शनाय महाचक्राय महाज्वालाय दीप्तरूपाय।

End:

ओं श्रीं ह्रीं क्लीं ऐं सहस्रार हुं फट् स्वाहा ॥

No. 7562. सुदर्शनमालामन्त्रः.
SUDARŚANAMĀLĀMANTRAḤ.

Pages, 8. Lines, 6 on a page.

Begins on fol. 17*b* of the MS. described under No. 5822.

Complete.

Similar to the above.

Beginning:

सुदर्शनमालामन्त्रः—

श्रीं ह्रीं क्लीं ऐं ओं सहस्रार हुं फट् । ओं नमो भगवते श्री-सुदर्शनमालामन्त्रमहाचक्रराजाय देवदेव जय जय विजय विजय अप-राजितापराजित अप्रतिहताप्रतिहत ।

End:

मां रक्ष रक्ष मम शत्रून्नाशय नाशय हन हन दह दह हुं फट् स्वाहा ॥

Colophon:

सुदर्शनमालामन्त्रः समाप्तः ॥

No. **7563.** सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 3*b* of the MS. described under No. 2886, wherein it is included in the Sudarśanamantra in the list of other works

Complete.

Similar to the above

Beginning:

ओं [अस्य] श्रीसुदर्शन चक्रराज देवदेव जय जय विजय विजय अनन्तानन्त अप्रतिहताप्रतिहत अनपायानपाय विकट विकट वीर वीर ।

End:

महाग्रहनिवारणाय श्रीमहाविष्णवे श्रूं शों हन हन हुं फट् स्वाहा ॥

No. **7564.** सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol 20*a* of the MS. described under No. 7517.

Complete.

Similar to the above.

Beginning:

ओं ह्रीं क्ली ऐं सुदर्शन महाचक्रराज देवदेव जय जय अपराजितापराजित अप्रतिहताप्रतिहत

End:

अपरिमितदिव्यास्त्रवीर्यतेजो(जउ)त्पादनाय कल्पान्तदहनाय महाविष्णवे क्ष्रौं हन दह हुं फट् स्वाहा ॥

Colophon:

श्रीमत्सुदर्शनमालामन्त्रः ॥

No. **7565.** सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Pages, 6. Lines, 16 on a page.

Begins on fol. 187*a* of the MS. described under No. 424, wherein it is given as Mahāsudraśanaprakaraṇam in the list of other works

Complete.

The repetition of this Mantra is considered to have the power of preventing the harm likely to be caused by evil spirits, serpents, cruel animals, etc.

Beginning:

अस्य श्रीसुदर्शनमालामन्त्रस्य अहिर्बुध्न्य ऋषिः, देवी गायत्री छन्दः, श्रीसुदर्शनस्वरूपश्रीमन्नारायणो देवता; रं बीजं, हुं शक्तिः, फट् कीलकं, रक्तवर्णप्रलयकालाग्निज्वालासुदर्शनप्रसादासिद्ध्यर्थे जपे विनियोगः ।

End:

यक्षराक्षसभूतप्रेतपिशाचासुरब्रह्मराक्षसादीन् पृथिव्यप्तेजोवाय्वाकाशादीन् सर्वदुष्टमुखज्वरचोरव्याघ्रसर्पादीन् बन्ध बन्ध अचलम(हा)चलमहावज्रकवचास्त्राय सुदर्शनाय सहस्रार हुं फट् स्वाहा ॥

No. 7566. सुदर्शनमालामन्त्रः.

SUDARŚANAMĀLĀMANTRAḤ.

Pages, 10. Lines, 6 on a page.

Begins on fol. 10*b* of the MS. described under No. 5822, wherein it is given as Sudarśanōccāṭanamantra in the list of other works.

Complete.

The repetition of this Mantra is considered to be efficacious in driving off one's enemies and in securing protection to one from all dangers.

Beginning:

ओं ठं रं क्ष्रौं ठं ग्रं क्रों सहस्रार हुं फट् स्वाहा ।

ओं नमो भगवते सुदर्शन महाचक्रराज सर्वदुष्टभयङ्कर मां रक्ष रक्षेनां रक्ष रक्ष मम शत्रूनुच्चाटयोच्चाटय ऐं क्षीं फट् स्वाहा ।

End:

ज्वालादीप्तरूपाय सर्वतो रक्ष मां महाज्वालामालाय स्वाहा हुं फट् स्वाहा । सं आचक्रायाङ्गुष्ठाभ्यां नमः . . . .
ज्वालाचक्राय वीर्यायास्त्राय फट् ॥

No. 7567. सुदर्शनषडक्षरीमन्त्रः.

SUDARŚANAṢAḌAKṢARĪMANTRAḤ.

Page, 1. Lines, 7 on a page.

Begins on fol. 14*a* of the MS. described under No. 7518.

Complete.

The repetition of this Mantra consisting of six syllables is intended to propitiate Sudarśana. The Mantra proper is not, however, given in the manuscript.

Beginning:

अस्य श्रीसुदर्शनषडक्षरीमहामन्त्रस्य अहिर्बुध्न्यो भगवानृषिः, अनुष्टुप् छन्दः, सुदर्शनो महाविष्णुः देवता ; ई बीजं, हं शक्तिः, फट्-कीलकं, श्रीसुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ध्यानम्—

शङ्खं चक्रं च चापं परशुमसिमिषुं शूलपाशाङ्कुशाग्नीन्
बिभ्राणं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्यायेत् षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥

मूलमन्त्रः ॥

No. 7568. सुदर्शनषडक्षरीमन्त्रः.

SUDARŚANAṢAḌĀKṢARĪMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 14*b* of the MS. described under No 6180.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसुदर्शनषडक्षरमहामन्त्रराजस्य अहिर्बुध्न्यो भगवानृषिः, देवी गायत्री छन्दः, श्रीसुदर्शनस्वरूपिश्रीमन्नारायणो देवता ; स्रं बीजं, हुं शक्तिः, फट् कीलकं, श्रीसुदर्शनप्रीत्यर्थे जपे विनियोगः ।

End:

ओं त्रैलोक्यं रक्ष रक्ष हुं फट् स्वाहा । ओं नमो भगवते महा-सुदर्शनाय हुं फट् ।

सुदर्शनाय विद्महे महाज्वालाय धीमहि ।
तन्नश्चक्रः प्रचोदयात् ॥

No. 7569. सुदर्शनषडक्षरीमन्त्रः.

SUDARŚANAṢAḌAKṢARĪMANTRAḤ

Page, 1. Lines, 19 on a page.

Begins on fol. 3*b* of the MS. described under No. 2886, wherein this is found in the Sudarśanamantra in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसुदर्शनषडक्षरीमहामन्त्रस्य अहिर्बुध्न्यभगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनरूपी महाविष्णुर्देवता, श्रीसुदर्शनमहाविष्णुप्रीत्यर्थे जपे विनियोगः, ह्रां बीजं, हुं शक्तिः, फट् कीलकं, सुदर्शनप्रीत्यर्थे जपे विनियोगः ।

End:

शङ्खं चक्रं च चापं परशुमसिमिषुं शूलपाशाङ्कुशाब्जं
बिभ्राणं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्याये षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥

* * * *

भूतान् त्रासय त्रासय मां रक्ष रक्ष हुं फट् सुदर्शनाय स्वाहा ॥

No. 7570. सुदर्शनाकर्षणमन्त्रः.

SUDARŚANĀKARṢAṆAMANTRAḤ.

Pages, 9. Lines, 6 on a page.

Begins on fol. 1*a* of the MS. described under No. 5822, wherein it has been omitted to be given as a separate work in the list of other works.

Complete.

The repetition of this Mantra is considered to have the power to enable one to forcibly bring one's enemies under subjection.

Beginning:

प्राणानायम्य, एवङ्गुणविशेषणविशिष्टायामस्यां शुभतिथौ श्रीभगवदाज्ञया भगवत्कैङ्कर्यरूपं भूतशुद्धिं करिष्ये ।

* * * *

अस्य श्रीसुदर्शनमहामन्त्रस्य अहिर्बुध्न्यो भगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनमहाविष्णुर्देवता ; ह्रां बीजं, ह्रीं शक्तिः, फट् कीलकं, सुदर्शनमहाविष्णुप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

आगच्छागच्छ मम शत्रूनाकर्षयाकर्षय ह्रीं क्रों आं वौषट् स्वाहा॥

No. **7571.** सुलोचनासिद्धिमन्त्रः.

SULŌCANĀSIDDHIMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 251*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* in the list of other works.

Complete.

This Mantra is addressed to a certain Yakṣiṇī named Sulōcanā; and its repetition accompanied with certain ceremonial acts is believed to have the power to propitiate her and make her confer on the worshipper a pair of sandals having certain mysterious supernatural powers.

Beginning:

षडङ्गन्यासं कुर्यात्। हेमप्राकारमित्यादिध्यानं पूर्ववत्।

मन्त्रः—

ब्लूं सुलोचने सिद्धिं देहि देहि स्वाहा।

End:

शतपत्रोद्भवे(न)पुष्पे(ण) घृतयुक्तेन त्रिविंशतिसहस्रं होमं कुर्यात्।

ततस्सुलोचना सिद्धा दद्यात्पादुकयोर्युगम्॥

No. **7572.** सुलोचनासिद्धिमन्त्रः.

SULŌCANĀSIDDHIMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 99*a* of the MS. described under No. 5566, wherein it has been omitted to be included in the list of other works

Complete.

Same as the above.

No. 7573. सुवर्णभैरवमन्त्रः.

SUVARṆABHAIRAVAMANTRAḤ.

Pages, 2. Lines, 27 on a page.

Begins on fol. 247*b* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* in the list of other works.

Complete.

This Mantra is addressed to Suvarṇabhairava; and its repetition is held to be efficacious in removing one's poverty.

Beginning:

अस्य श्रीसुवर्णभैरवमन्त्रस्य दूर्वास ऋषिः, गायत्री छन्दः, सुवर्णभैरवो देवता; वं बीजं, ह्रीं शक्तिः, मम दारिद्र्यहरणार्थे विनियोगः ।

End:

ओं वं ह्रीं सुवर्णाकर्षणाय मम दारिद्र्यापहाराय ह्रीं स्वाहा ॥

No. 7574. सुवर्णभैरवमन्त्रः.

SUVARṆABHAIRAVAMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 97*a* of the MS. described under No. 5566, wherein it has been given as beginning on fol. 101.

Complete.

Same as the above.

No. 7575. सुवर्णभैरवमन्त्रः.

SUVARṆABHAIRAVAMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 11*b* of the MS. described under No. 5828.

Complete.

Similar to the above

Beginning:

अस्य श्रीसुवर्णभैरवमहामन्त्रस्य [गायत्री छन्दः] भार्गव ऋषिः, अनुष्टुप् छन्दः, सुवर्णाकर्षणश्रीमहाभैरवो देवता; ह्रां बीजं, ह्रीं शक्तिः, मम दारिद्र्यविनाशनसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं वं रं द्रौं त्रं ह्रीं महाभैरवाय आपदुद्धारणाय अजामिलबन्धनाय लोकेश्वराय सुवर्णाकर्षणाय दारिद्र्यापहरणाय ह्रीं ह्रीं ह्रूं लं स्वाहा ॥

No. **7576.** सूर्यकवचः.

SŪRYAKAVACAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 23*a* of the MS. described under No. 129.

Complete as found in the Skāndapurāṇa.

The repetition of this Mantra which is addressed to the sun-god is considered to be efficacious in removing diseases, in conferring on a person good health and in enabling him to accomplish his desires.

Beginning:

अस्य श्रीसूर्यकवचस्तोत्रमन्त्रस्य श्रीसूर्यनारायण ऋषिः, श्रीसूर्यनारायणो देवता, अनुष्टुप् छन्दः, ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, मम समस्ताभीष्टसिद्ध्यर्थे शरीरारोग्यसिद्ध्यर्थे जपे विनियोगः ।

घृणिः पातु शिरो नित्यं ललाटं पातु भास्करः ।
आदित्यो मे दृशौ पातु श्रोत्रे पातु दिवाकरः ॥

End:

समस्ताभीष्टसंप्राप्तिः सूर्यलोकं स गच्छति ।
सततं प्रातरुत्थाय सर्वरोगाद्विमुच्यते ॥

Colophon:

इति श्रीस्कान्दे पुराणे रोगनाशनरत्नाकरे सूर्यकवचस्तोत्रं संपूर्णम् ॥

No. **7577.** सूर्यकवचः.

SŪRYAKAVACAḤ.

Pages, 9. Lines, 6 on a page.

Begins on fol. 8*a* of the MS. described under No. 6393.

Complete. This is also taken from the Skāndapurāṇa.

Similar to the above. Held also to have the power to propitiate the sun-god, to destroy one's enemies, to bring people under one's control and influence and to accomplish one's desires.

Beginning:

देवासुरैस्सदा वन्द्यं ग्रहैश्च परिवेष्टितम् ।
ध्यायन् पठेत्सुवर्णाभं श्रीसूर्यकवचं सदा ॥

अस्य श्रीसूर्यकवचस्तोत्रमहामन्त्रस्य गिरिजा ऋषिः, अनुष्टुप् छन्दः, श्रीसूर्यनारायणो देवता, मम सकलशत्रुक्षयार्थे इष्टकाम्यार्थसिद्ध्यर्थे लोकवशीकरणार्थे श्रीसूर्यनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

सूर्यभक्तिप्रसन्नात्मा यः करे धारयेत् सुधीः ।
भुक्त्वा तु सकलान् भोगान् सूर्यलोके प्रशस्यते ॥
उदयं ब्रह्मस्वरूपं मध्याह्नं च महेश्वरम् ।
अस्तमनं स्वयं विष्णुं त्रयीमूर्तिर्दिवाकरः(?) ॥

Colophon:

इति स्तोत्ररत्नाकरे श्रीसूर्यकाण्डे रोगनाशाय स्कान्दपुराणे गौर्या प्रोक्तं श्रीसूर्यकवचं संपूर्णम् ॥

No. 7578. सूर्यकवचः.

SŪRYAKAVACAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 19*a* of the MS. described under No. 5781.

Complete. Similar to the above.

This is also taken from the Skāndapurāṇa.

Beginning:

अस्य श्रीसूर्यकवचस्तोत्रमन्त्रस्य गौतम ऋषिः, अनुष्टुप् छन्दः, श्रीसूर्यनारायणो देवता ।

देवासुरैस्सदा वन्द्यं ग्रहैश्च परिवेष्टितम् ।
ध्यायन् पठन् सुवर्णाभं श्रीसूर्यकवचं सदा ॥

End:

सर्वान् कामानवाप्नोति विष्णुलोके महीयते ।
सततं प्रातरुत्थाय पठेद्रोगाद्विमुक्तवान् ॥

Colophon:

इति स्तोत्ररत्नाकरे रोगनाशकस्कान्दपुराणे श्रीसूर्यकवचस्तोत्रं संपूर्णम् ॥

No. 7579. सूर्यकवचः.
SŪRYAKAVACAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 107*a* of the MS. described under No. 5661, wherein it is given as Ādityakavaca in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसूर्यकवचस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीसूर्यनारायणो देवता, मम सकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

देवासुरैस्सदा सेव्यं ग्रहैश्च परिवेष्टितम् ।
ध्यायेत्पठेत्सुवर्णाभं श्रीसूर्यकवचं मुदा ॥

* * * *

घृणिः पातु शिरोदेशं सूर्यः फालं दिवाकरः ।
घ्राणं पातु सदा भानुः अर्कः पातु मुखं तथा ॥

End:

संवत्सरमुपासित्वा मनस्सिद्धिं व्रजेत्पुमान् ।
इदन्तु कवचं बद्ध्वा विचरोद्विगतज्वरः ॥

Colophon:

श्रीसूर्यकवचं संपूर्णम् ॥

No. 7580. सूर्यकवचः.
SŪRYAKAVACAḤ.

Pages, 2. Lines, 22 on a page.

Begins on fol. 15*b* of the MS. described under No. 6045.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसूर्यकवचस्तोत्रमहामन्त्रस्य गिरिराज ऋषिः, अनुष्टुप् छन्दः, आदित्यो देवता; ओं बीजं, श्रीं शक्तिः, नमः कीलकं, मम समस्तपापक्षयार्थे जपे विनियोगः ।

End:

सततं प्रातरुत्थाय यस्सूर्यकवचं पठेत् ।
सर्वशूलविनाशाय सूर्यलोकमुपैति (सः) ॥

No. 7581. सूर्यकवचः.
SŪRYAKAVACAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 24*b* of the MS. described under No. 5789, wherein this work has been omitted to be mentioned in this list of other works.

Complete.

Similar to the above.

Beginning:

अधुना संप्रवक्ष्यामि कवचं सर्वकामदम् ।
इदं तु कवचं बध्द्वा विचरेद्विगतज्वरः ॥
सौरस्य कवचस्यर्षिर्जगन्माता महेश्वरी ।
छन्दोऽनुष्टुप् देवतार्क इष्टार्थे विनियुज्यते ॥

End:

सावित्रं कवचं प्रातर्मध्याह्ने वापि भास्करम् ।
पश्यन् पठेत् प्रतिदिनं पापजालैर्न लिप्यते ॥
इदं पठन्नमस्कुर्यात् प्रातर्मध्याह्नयो रविम् ।
सर्वान् कामानवाप्नोति तेजसार्कसमो भवेत् ॥

Colophon:

इति सूर्यकवचं सम्पूर्णम् ॥

No. **7582.** सूर्यकवचः.
SŪRYAKAVACAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 12*a* of the MS. described under No. 5938

Complete.

Similar to the above.

Beginning:

देवासुरैस्सदा वन्द्यं ग्रहैश्च परिवेष्टितम् ।
ध्यायन् पठेत्सुवर्णाभं श्रीसूर्यकवचं सुधीः ॥

अस्य श्रीसूर्यकवचस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप् छन्दः, सूर्यनारायणो देवता, सर्वव्याधिविनाशनरोगहरणे मम समस्तपापक्षयार्थे श्रीसूर्यनारायणप्रीत्यर्थे विनियोगः । . . . .

घृणिः पातु शिरो नित्यं ललाटं पातु भास्करः ।

End:

पूर्वमेतत्कृतं गौर्या विचिन्त्याखिलकामदम् ।
कवचं प्रातरुत्थाय पठन् रोगैर्विमुच्यते ॥

No. **7583.** सूर्यकवचः.
SŪRYAKAVACAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 21*a* of the MS. described under No. 831.

Complete as found in the Skāndapurāṇa

Similar to the above.

Beginning:

देवासुरैस्सदा वन्द्यं ग्रहैश्च परिवेष्टितम् ।
ध्यात्वा पठेत् सुवर्णाभं श्रीसूर्यकवचं सदा ॥

End:

सर्वसिद्धिमवाप्नोति विष्णुलोके महीयते ।
सततं प्रातरुत्थाय पठन् रोगात् प्रमुच्यते ॥

Colophon :

इति स्कान्दपुराणे सूर्यकवचम् ॥

No. **7584.** सूर्यकवचः.
ŚŪRYAKAVACAḤ.

Pages, 4. Lines, 4 on a page.

Begins on fol. 47*b* of the MS. described under No. 6101, wherein it has been wrongly stated to begin on fol. 46*a*.

Complete.

Similar to the above.

Beginning :

अस्य श्रीसूर्यकवचस्तोत्रमन्त्रस्य अनुष्टुप् छन्दः, श्रीसूर्यनारायणो देवता, मम समस्तपापक्षयार्थे श्रीसूर्यनारायणप्रीत्यर्थे विनियोगः ।

End :

इदं मे प्र(पूर्वमेतत)कृतं गौर्या विचिन्त्याखिलकामदम् ।
सततं प्रातरुत्थाय सर्व(पठन्)रोगाद्विमुच्यते ॥

For the colophon, see under the previous number.

No. **7585.** सूर्यग्रहमन्त्रः.
SŪRYAGRAHAMANTRAḤ.

Pages. 2. Lines. 5 on a page.

Begins on fol. 12*b* of the MS. described under No. 5864, wherein this is given under the name of Ādityagrahamantra in the list of other works.

Complete.

This is the same as the Sauramantra. This Mantra is also addressed to Sūrya. It differs somewhat from that which is found in the 15th Anuvāka in the 6th Prapāṭhaka of the Taittirīya Āraṇyaka.

Beginning :

अस्य श्रीआदित्यमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, सूर्यादित्यो देवता; ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं; श्रीशरभसाल्वप्र—गः ।

End:

घृणिस्सूर्य आदित्यों न प्रभावात्यक्षरम् मधु क्षरन्ति तद्रसं सत्यं नैतद्रसमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवस्सुवरों ॥

No. **7586.** सूर्यनमस्कारमन्त्रः.

SŪRYANAMASKĀRAMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 121*a* of the MS. described under **No.** 5661.

Complete.

This Mantra is repeated during the performance of the reverential prostration before the sun-god, which form of worship is considered to be efficacious in removing all diseases from one's body and in wiping off one's sins.

Beginning:

शुकं भागवते व्यासं वेदे वत्ते च तद्गुरुम् ।
तत्पितामहमाचारे वन्दे श्रीकृष्णदेशिकम् ॥

एवङ्गुणतिथौ मम समस्तपापक्षयार्थं मम शरीरे वर्तमानवर्तिष्यमाणसूचितआगामिसमस्ताधिव्याध्यादिरोगानिवृत्त्यर्थं श्रीछायासमेतश्रीसूर्यनारायणप्रीत्यर्थं सूर्यनमस्कारान् करिष्ये—

ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्य मित्रमहः ।

End:

धातार्यमा च मित्रश्च वरुणोऽशर्भ(शो भ)गस्तथा ॥
विवस्वदिन्द्रौ पूषा च पर्जन्यश्च तथैव च ।
त्वष्टा च विष्णुरित्येवं नामानि द्वादशात्मनः ॥

No. **7587.** सूर्यनारायणकवचः.

SŪRYANĀRĀYAṆAKAVACAḤ.

Pages, 3. Lines, 18 on a page.

Begins on fol. 5*a* of the MS. described under No. 2373.

Complete. This Mantra is taken from the Skāndapurāṇa.

Similar to No. 7576.

Beginning:

अस्य श्रीसूर्यनारायणकवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, श्रीसूर्यनारायणो देवता; ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, श्रीसूर्यनारायणप्रसादसिद्ध्यर्थे प्रीत्यर्थे जपे विनियोगः ।

* * * *

आदित्यो मे शिरः पातु ललाटं पातु भास्करः ।
प्राणं पातु सदा सूर्यः श्रुती पातु दिवाकरः ॥

End:

इदं सूर्यं प्रगे नत्वा यः करे धारयिष्य(ति) ।
. . . . . श्रीसूर्यलोकं स गच्छति ॥

Colophon:

इति स्कान्दपुराणे आदिकाण्डे उमामहेश्वरसंवादे श्रीसूर्यनारायण-कवचं समाप्तम् ॥

No. 7588. सूर्यनारायणकवचः.

SŪRYANĀRĀYAṆAKAVACAḤ.

Pages, 4. Lines, 6 on a page.

Begins on fol. 4*a* of the MS. described under No. 365.
Complete.
Same as the above.

No. 7589. सूर्यनारायणकवचः.

SŪRYANĀRĀYAṆAKAVACAḤ.

Pages, 5. Lines, 5 on a page.

Begins on fol. 36*b* of the MS. described under No. 5937.
Complete as found in the Skāndapurāṇa.
Similar to the above.

Beginning:

अस्य श्रीसूर्यनारायणकवचस्तोत्रमन्त्रस्य गौतम ऋषिः, अनुष्टुप् छन्दः, श्रीसूर्यनारायणो देवता; ह्रीं बीजं, ह्रां शक्तिः, श्रीसूर्यनारायणेति कीलकं. श्रीसूर्यनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।

* * * *

घृणिः पातु शिरो नित्यं ललाटं पातु भास्करः ।
आदित्यो मे दृशौ पातु श्रोत्रे पातु दिवाकरः ॥

End:

षण्मासं सर्वकार्यार्थं संवत्सरमुपासितम् ।
सर्वसिद्धिमवाप्नोति विष्णुलोके महीयते ॥

Colophon:

इति स्कन्दपुराणे सूर्यनारायणकवचं सम्पूर्णम् ॥

No. 7590. सूर्यनारायणमन्त्रः.

SŪRYANĀRĀYAṆAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 85*b* of the MS. described under No. 235, wherein it has been wrongly stated to begin on fol. 86*a*.

Complete.

The repetition of this Mantra, followed by the pouring of oblations of water, is believed to have the power to propitiate the sun-god who is conceived as Nārāyaṇa.

Beginning:

एवं गु . . शुभतिथौ मम दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीसूर्यनारायणमुद्दिश्य श्रीसूर्यनारायणप्रीत्यर्थं पुरश्चरणाङ्गतर्पणं करिष्ये ।

End:

आदित्याय स्वाहा—सूर्यायेदं न मम । श्रीसूर्यनारायणश्रीपादुकां पूजयामि तर्पयामि नमः ॥

No. 7591. सूर्यमन्त्रः.

SŪRYAMANTRAḤ.

Pages, 1. Lines, 18 on a page.

Begins on fol. 310*a* of the MS. described under No. 5477, wherein this is included in the Mantramālikā (Ākāśabhairavakalpā) 273*a* mentioned in the list of other works.

Complete.

The repetition of this Mantra, followed by a fire-offering, is considered to have the power to propitiate the sun-god.

Beginning:

अस्य श्री-आदित्यमन्त्रस्य हिरण्य ऋषिः, त्रिष्टुप् छन्दः, सविता दवता, मम सूर्यप्रसादसिद्ध्यर्थे विनियोगः ।

End:

ओं ह्रां आदित्याय नमः । लक्षं जपः । दशांशहोमः ॥

No. 7592. सूर्याष्टाक्षरमन्त्रः.

SŪRYĀṢṬĀKṢARAMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 29*a* of the MS. described under No. 5786.

Complete.

This Mantra consists of eight syllables, and is taken from the 15th Anuvāka in the 6th Prapāṭhaka of the Taittirīya Āraṇyaka. The syllable Ōm, occurring both in the beginning and in the end, is not to be taken as forming part of the Mantra proper.

Beginning:

ओं घृणिस्सूर्य आदित्य ओं इति प्राणायामः १२ ।

* * * *

अस्य श्रीसूर्याष्टाक्षरमन्त्रस्य कौशिक ऋषिः, देवभाग ऋषिर्वा, गायत्री छन्दः, सूर्यो देवता, सूर्यप्रेरणया सूर्यप्रीत्यर्थे जपे विनियोगः ।

End:

सूर्यप्रेरणया सूर्यप्रीत्यर्थं सूर्यमहामन्त्रजपङ्करिष्ये । ओं घृणिस्सूर्य आदित्यः ओं इति जपः । उपसंहारः पूर्ववत् ॥

No 7593. सौभाग्यकवचम्.

SAUBHĀGYAKAVACAM.

Substance, paper. Size, $9\frac{3}{4} \times 7\frac{3}{4}$ inches. Pages, 10. Lines, 20 on a page. Character, Telugu. Condition, good, Appearance, new.

Begins on fol. 121*a*. The other works herein are Dakṣiṇāmūrtisaṁhitā 1*a*. Bhuvanēśvarīkacchapuṭa 65*a*, Mahālakṣmīratnakōśa 105*a*, Gāyatrīcakra 126*a*, Navacaṇḍīpūjā 132*a*, Divyamaṅgalādhyāna 137*a*.

Complete as found in the Nityāṣōḍaśikārṇava forming part of the Vāmakēśvaratantra.

This Kavaca-mantra is addressed to Tripurasundarī; and its repetition is considered to have the power of conferring prosperity on the worshipper and of bringing under his control all the three worlds.

Beginning:

कैलासशिखरे रम्ये सुखासीनं सुरार्चितम् ।
गिरीशं गिरिजा स्तुत्वा स्तोत्रैर्वेदान्तपारगैः ॥

* * * *

एतत्सौभाग्यकवचं रहस्यातिरहस्यकम् ।
सौभाग्यकवचं देवि शृणु सौभाग्यदायकम् ॥

वाक्यम्—

अस्य श्रीसौभाग्यकवचस्तोत्रमहामन्त्रस्य आनन्दभैरव ऋषिः, अनुष्टुप् छन्दः, सौभाग्यसुन्दरी देवता; ऐं क्लीं सौः बीजं, ह्रीं क्लीं शक्तिः, आं ह्रीं क्रों कीलकं, मम सौभाग्यसिद्ध्यर्थे जपे विनियोगः ।

* * * *

शिखाग्रे सततं पातु नमस्त्रि(मम त्रि)पुरसुन्दरी(म्) ।
शिरः कामेश्वरी नित्या तत्पूर्वं भगमालिनी ॥

End:

वश्यं भवतु(ति) शीघ्रेण त्रैलोक्यं सचराचरम् ।
आबालमहिला भूपाः किमु मायाविमोहिताः ॥

Colophon :

इति वामकेश्वरतन्त्रे नित्याषोडशिकार्णवे सौभाग्यकवचं सम्पूर्णम् ॥

No. 7594. सौभाग्यकवचम्.

SAUBHĀGYAKAVACAM.

Pages, 2. Lines, 19 on a page.

Begins on fol. 55*a* of the MS. described under No. 2886.

Complete as found in the Nityāṣōḍaśikārṇava.

Similar to the above.

Beginning :

कैलासशिखरे रम्ये सुखासीनं सुरार्चितम् ।
गिरीशं गिरिजा नत्वा स्तोत्रैर्वेदार्थगर्भितैः ॥
प्रणम्य परया भक्त्या ततोऽपृच्छत्कृताञ्जलिः ।

* * * *

ईश्वर उवाच—

एतत्सौभाग्यकवचं रहस्यातिरहस्यकम् ।
सौभाग्यकवचं देवि शृणु सौभाग्यदं परम् ॥
शिखायां (खां मे)सततं पातु महात्रिपुरसुन्दरी ।
शिरः कामेश्वरी नित्या तत्पूर्वं भगमालिनी ॥

End :

वश्यं भवति शीघ्रेण त्रैलोक्यं सचराचरम् ।
भूपालमहिला भूपा म(म)मायाविमोहिताः ॥

Colophon :

इति नित्याषोडशिकार्णवे सौभाग्यकवचं समाप्तम् ॥

No. 7595. सौभाग्यकवचम्.

SAUBHĀGYAKAVACAM.

Pages, 3. Lines, 10 on a page.

Begins on fol. 241*a* of the MS. described under No. 124, wherein it is given under the name of Lalitākavaca in the list of other works.

Complete as found in the 33rd Paṭala of the Nityāṣōḍaśikārṇava forming part of the Vāmakēśvaratantra.

Similar to the above.

Beginning :

इक्षुकोदण्डपुष्पेषुपाशाङ्कुशचतुर्भुजाम् ।
उद्यत्सूर्यनिभां वन्दे महात्रिपुरसुन्दरीम् ॥
कैलासशिखरे रम्ये सुखासीनं सुरार्चितम् ।
गिरीशं गिरिजा नित्यं स्तोत्रैर्वेदार्थगर्भितैः ॥
प्रणम्य परया भक्त्या तमपृच्छत् कृताश्रया ।

* * * *

सौभाग्यकवचं देवि शृणु सौभाग्यदायकम् ।
शिखाग्रे(खां मे) सततं पातु महात्रिपुरसुन्दरी ॥
शिरः कामेश्वरी नित्यं पूर्वं तु भगमालिनी ।
नित्यक्लिन्ना तु तद्दक्षं भेरुण्डी पश्चिमं शिरः ॥

End:

वश्यं भवति शीघ्रेण त्रैलोक्यं सचराचरम् ।
भूपालमखि(हि)ला भूपाः किमुपाया विमोहिताः ॥
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।
मुकुन्दकुन्दनीलाश्च वराश्च निधयो नव ॥

Colophon :

इति श्रीवामकेश्वरतन्त्रे नित्याषोडशिकार्णवे सौभाग्यकवचं नाम त्रयस्त्रिंशः पटलः ॥

श्रीसौभाग्यकवचं संपूर्णम् ॥

No. 7596. सौभाग्यकवचम्.

SAUBHĀGYAKAVACAM.

Pages, 10. Lines, 16 on a page.

Begins on fol. 37*a* of the MS. described under No. 424.

Complete.

Similar to the above.

Beginning :

Same as that of the above with the first stanza omitted.

End :

तत्पादकमलासक्तरजोलेशानि(भि)मर्शनात् ॥
प(व)श्यन्ति वनिता(:) शीघ्रं त्रैलोक्यं सचराचरम् ।
भूपालमहिला भूपाः किमु मायाविमोहिताः ॥

Colophon :

इति श्रीवामकेश्वरतन्त्रशास्त्रे षोडशार्णवे सौभाग्यकवचं नाम त्रयस्त्रिशः पटलः समाप्तः ॥

No. 7597. सौभाग्यविद्यामन्त्रः.

SAUBHĀGYAVIDYĀMANTRAḤ.

Page, 1. Lines, 7 on a page.

Begins on fol. 4*b* of the MS. described under No. 673, wherein this Mantra is included in the Ṣaḍāmnāya 1*a* given in the list of other works.

Complete.

The repetition of this Mantra is believed to have the power to propitiate Tripurasundarī and to bestow prosperity on the worshipper.

Beginning :

अस्य श्रीसौभाग्यविद्यामहामन्त्रस्य आनन्दभैरव ऋषिः, अमृतविराट् छन्दः, श्रीमहात्रिपुरसुन्दरी देवता; क ए ई ल ह्रीं बीजं, ह स क ह ल ह्रीं शक्तिः, स क ल ह्रीं कीलकं, मम श्रीमहात्रिपुरसुन्दरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौभाग्याम्बाश्रीपा—नमः ॥

No. **7598.** सौभाग्यविद्यामन्त्रः.

SAUBHĀGYAVIDYĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 22a of the MS. described under No. 5852.

Complete.

Similar to the above.

Held also to have the power to enable one to accomplish the four Purusārthas or principal aims of life, viz., Dharma, Artha Kāma and Mōkṣa.

Beginning:

अस्य श्रीसौभाग्यविद्येश्वरीब्रह्मविद्यामहामन्त्रस्य परमानन्दभैरव ऋषिः गायत्री छन्दः, श्रीसौभाग्यविद्येश्वरी ब्रह्मविद्या देवता; ऐं क ए ई ल ह्रीं बीजं, क्लीं ह स क ह ल ह्रीं शक्तिः, सौः स क ल ह्रीं कीलकं, श्रीसौभाग्यविद्येश्वरीब्रह्मविद्याप्रसादसिद्ध्यर्थे मम चतुर्विधफलपुरुषार्थे जपे विनियोगः ।

End:

क ए ई ल ह्रीं ह स क (ह)ल ह्रीं स क ल ह्रीं ॥

No. **7599.** सौभाग्यविद्यामन्त्रः.

SAUBHĀGYAVIDYĀMANTRAḤ.

Pages, 2. Lines, 14 on a page.

Begins on fol. 170a of the MS. described under No. 5673, wherein it is given as Saubhāgyavidyāmālāmantra in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसौभाग्यविद्यामहामन्त्रस्य दक्षिणामूर्तिः ऋषिः, पङ्क्तिश्छन्दः, षोढास्वरूपा श्रीपराम्बा देवता; ऐं क ए ई ल ह्रीं बीजाय नमः, क्लीं ह स क ह ल ह्रीं शक्तये नमः, सौः स क ल ह्रीं कीलकाय (नम):, श्रीमहात्रिपुरसुन्दरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥

पञ्चपूजां कुर्यात् ॥

No. 7600. सौभाग्यविद्यामन्त्रराजमन्त्रः.

SAUBHĀGYAVIDYĀMANTRARĀJAMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 230*a* of the MS. described under No. 124, wherein this is included in the Ṣaḍāmnāya 228*b* contained in the list of other works.

Complete.

Similar to the above.

Beginning :

अथ दक्षिणाम्नायः ।

सौभाग्यविद्या बगला वाराही वटुकस्तथा ।
श्रीतिरस्करिणी प्रोक्ता दक्षिणाम्नायदेवताः ॥

* * * *

अस्य श्रीसौभाग्यविद्यामन्त्रराजमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः, पङ्क्तिश्छन्दः, सौभाग्यविद्येश्वरी ब्रह्मविद्याम्बा देवता ; ऐं क ए ई ल ह्रीं बीजं, सौः स क ल ह्रीं शक्तिः, क्लीं ह स क ह ल ह्रीं कीलकं, मम सौभाग्यविद्येश्वरीब्रह्मविद्याम्बाप्रसा—गः ।

End :

ओं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौभाग्यविद्येश्वरीब्रह्मविद्याम्बादिव्यश्री—मः ॥

No. **7601.** सौभाग्यविद्येश्वरीमन्त्रः.

SAUBHĀGYAVIDYĒŚVARĪMANTRAḤ.

Pages, 6. Lines, 14 on a page.

Begins on fol. 14*a* of the MS. described under No. 5673, wherein this is included in the Āmnāyamantramālikā 1*a* given therein in the list of other works.

Complete.

This Mantra is addressed to Saubhāgyavidyēśvarī or Tripurasundarī and consists of 15 syllables. Its repetition is intended to propitiate that goddess.

Beginning:

अस्य श्रीसौभाग्यविद्येश्वरीराजराजेश्वरीत्रिपुरसुन्दरीब्रह्मविद्यापञ्चदशाक्षरीमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः, पङ्क्तिश्छन्दः, श्रीसौभाग्यविद्येश्वरी ब्रह्मविद्या त्रिपुरसुन्दरी देवता ; क ४ बीजं; स ३ शक्तिः, ह ९ कीलकं, मम श्रीसौभाग्यविद्येश्वरीराजराजेश्वरीत्रिपुरसुन्दरीब्रह्मविद्यापञ्चदशाक्षरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—

क ४, ह ५, स ३, श्रीसौभाग्यविद्याम्बा श्रीः

No. **7602.** सौभाग्यविद्येश्वरीमन्त्रः.

SAUBHĀGYAVIDYĒŚVARĪMANTRAḤ.

Pages, 2. Lines, 14 on a page.

Begins on fol. 42*a* of the MS. described under No. 5673, wherein this is included in the Āmnāyamantramālikā 1*a* given in the list of other works.

Incomplete.

Similar to the above.

Beginning:

अस्य श्रीसौभाग्यविद्येश्वरीराजराजेश्वरीत्रिपुरसुन्दरीब्रह्मविद्यापञ्चदशाक्षरीमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः, पङ्क्तिश्छन्दः, श्रीसौभाग्यविद्येश्वरी

ब्रह्मविद्या पञ्चदशाक्षरी देवता; ऐं क ४ बीजं, सौः स ३ शक्तिः, क्लीं ह ५ कीलकं, मम श्रीसौभाग्यविद्येश्वरीराजराजेश्वरीप्रसादसिद्ध्यर्थे जपे विनियोगः।

End:

पञ्चपूजा। ऐं क ४, क्लीं ह ५, सौः स ३, श्रीसौभाग्यविद्या-श्री।

ऐं क ४, क्लीं ह ५, सौः स ३, ईशानाय नमः—मूर्ध्नि,. . . . . सद्योजाताय नमः—पादयोः॥

No. 7603. सौभाग्यविद्येश्वरीमन्त्रः.

SAUBHĀGYAVIDYEŚVARĪMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 6*b* of the MS. described under No. 5686.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसौभाग्यविद्येश्वरीपरब्रह्मविद्यामहामन्त्रस्य आनन्ददाक्षिणामूर्तिभैरव ऋषिः, अनुष्टुप् छन्दः, श्रीसौभाग्यविद्येश्वरी देवता; ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, मम सौभाग्यविद्येश्वरीप्रसादसिद्ध्यर्थे जपे विनियोगः।

End:

मूलम्—

ओं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः

* * * *

अनन्तकोटिमन्त्ररूपिणि अनन्तमूर्ति परिशोधयामि जुहोमि स्वाहा संविन्मन्त्रमयमे(व)किञ्चिदधिकं भवति॥

No. 7604. सौभाग्यविद्येश्वरीमन्त्रः.

SAUBHĀGYAVIDYEŚVARĪMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 56*a* of the MS. described under No. 5661.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसौभाग्यविद्येश्वरीब्रह्मविद्यात्रिपुरसुन्दरीमहामन्त्रस्य परब्रह्म ऋषिः, गायत्री छन्दः, श्रीसौभाग्यविद्येश्वरी ब्रह्मविद्या त्रिपुरसुन्दरी देवता; क ए ई ल ह्रीं बीजं, ह स क ह ल ह्रीं शक्तिः, स क ल ह्रीं कीलकं, मम सौभाग्यविद्येश्वरीब्रह्मविद्यात्रिपुरसुन्दरीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

वं अमृतात्मकायै श्रीमहात्रिपुरसुन्दर्यै सौभाग्यविद्येश्वरि अमृतनैवेद्यं कल्पयामि ।

मनुः—

क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं ॥

No. 7605. सौरचतुरक्षरीमन्त्रः.

SAURACATURAKṢARĪMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 291*b* of the MS. described under No. 5477, wherein it is contained in the Mantramālikā (Ākāśabhairava-kalpa) 273*a* given in the list of other works.

Complete.

The repetition of this Mantra consisting of four syllables is considered to have the power to propitiate the sun-god.

Beginning:

अस्य श्रीसौरचतुरक्षरीमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, सूर्यात्मिका भुवनेश्वरी देवता, ओं बीजं, ह्रीं शक्तिः, श्रीसौरप्रीत्यर्थे विनियोगः ।

End :

ओं ह्रीं हं सः । जपहोमः पूर्ववत् ॥

No. 7606. सौरचतुरक्षरीमन्त्रः.

SAURACATURAKṢARĪMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 247*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* given in the list of other works.

Complete.

Same as the above.

No. 7607. सौरचतुरक्षरीमन्त्रः.

SAURACATURAKṢARĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 96*b* of the MS. described under No. 5566, wherein it has been omitted to be included in the list of other works.

Complete.

Same as the above.

No. 7608. सौराष्टाक्षरीमन्त्रः.

SAURĀṢṬĀKṢARĪMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 12*b* of the MS. described under No. 5686.

Complete

This is the eight-syllabled Mantra addressed to the sun-god, and is taken from the 15th Anuvāka in the 6th Prapāṭhaka of the Taittirīya Āraṇyaka. Its repetition is intended to secure the favour of the sun-god conceived as Nārāyaṇa.

Beginning :

अस्य श्रीसौराष्ट्(ष्टाक्षरी)महामन्त्रस्य सवितृभगवानृषिः, अनुष्टुप् छन्दः, श्रीसूर्यनारायणो देवता, श्रीसूर्यनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

गोजा ऋतजा अद्रिजा ऋतं बृहत् । ओं श्रीं ह्रीं घृणिस्सूर्य आदित्यों ॥

No. **7609.** सौराष्टाक्षरीमन्त्रः.

SAURĀṢṬĀKṢARĪMANTRAḤ.

Pages, 2. Lines, 14 on a page.

Begins on fol. 36*b* of the MS. described under No. 5673, wherein it is included in the Āmnāyamantramālikā given in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसौराष्टाक्षरीमन्त्रस्य भगवानृषिः, गायत्री छन्दः, श्रीसूर्यनारायणो देवता, घृणिरिति बीजं, सूर्येति शक्तिः, आदित्येति कीलकं, मम श्रीसूर्यनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—

घृणिस्सूर्य आदित्य ओं । सौरमयविद्याश्री इति हृदये च पूजयेत् ॥

No. **7610.** सौराष्टाक्षरीमन्त्रः.

SAURĀṢṬĀKṢARĪMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 39*a* of the MS. described under No. 5937.

Complete.

Similar to the above

Beginning:

अस्य श्रीसौराष्टाक्षरीमहामन्त्रस्य काश्यप ऋषिः, त्रिष्टुप् छन्दः, श्रीसूर्यनारायणो देवता; घृणिरिति बीजं, सूर्येति शक्तिः, आदित्योमिति कीलकं, श्रीसूर्यनारायणप्रीत्यर्थे विनियोगः ।

End:

रं वह्न्यात्मने भानवे नमः—दीपं, वं अमृतात्मने हिरण्यगर्भाय नमः—नैवेद्यम् ॥

No. **7611.** सौराष्टाक्षरीमन्त्रः.

SAURĀṢṬĀKṢARĪMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 291*b* of the MS. described under No. 5477, wherein it is found in the Mantramālikā (Ākāśabhairavakalpa) 273*a*, mentioned in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसौराष्टाक्षरीमन्त्रस्य देवभाग ऋषिः, गायत्री छन्दः, सूर्यो देवता ; ओं बीजं, ण्यं शक्तिः, सौराष्टाक्षरीप्रीत्यर्थे जपे विनियोगः ।

End

घृणिस्सूर्य आदित्यों । चतुर्लक्षजपपुनश्चरणम् । अयुतहोमः ॥

Colophon:

इति सौराष्टाक्षरी ॥

No. **7612.** सौराष्टाक्षरीमन्त्रः.

SAURĀṢṬĀKṢARĪMANTRAḤ.

Page, 1. Lines, 27 on a page.

Begins on fol. 247*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a*.

Complete.

Same as the above; but there is no colophon.

No. **7613.** सौराष्टाक्षरीमन्त्रः.

SAURĀṢṬĀKṢARĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 96*b* of the MS. described under No. 5566, wherein it is wrongly stated in the list of other works to begin on fol. 100.

Complete.

Same as the above.

No. 7614. सौराष्टाक्षरीमन्त्रः.
SAURĀṢṬĀKṢARĪMANTRAḤ.

Page, 1. Lines, 7 on a page.

Begins on fol. 16*a* of the MS. described under No. 371.

Complete.

Similar to the above.

Beginning:

अस्य श्रीसौराष्टाक्षरीमहामन्त्रस्य देवो भगवानृषिः, अनुष्टुप् छन्दः; श्रीसूर्यनारायणो देवता; घृणिरिति बीजं, सूर्य इति शक्तिः, आदित्य इति कीलकं, श्रीसूर्यनारायणप्रसादासिद्ध्यर्थे जपे विनियोगः।

End:

श्रीं ह्रीं क्लीं घृणिस्सूर्य आदित्यों क्लीं ह्रीं श्रीं पञ्चोपचारैस्संपूज्य ॥

No. 7615. सौराष्टाक्षरीमन्त्रः.
SAURĀṢṬĀKṢARĪMANTRAḤ.

Page, 1. Lines, 19 on a page.

Begins on fol. 14*a* of the MS. described under No. 2886.

Complete.

Similar to the above

Beginning:

अस्य श्रीसौराष्टाक्षरीमहामन्त्रस्य देवभाग ऋषिः, गायत्री छन्दः, सूर्यनारायणो देवता; घृणिरिति बीजं, सूर्य इति शक्तिः, आदित्यो-मिति कलिकं, सूर्यनारायणप्रीत्यर्थे जपे विनियोगः।

End:

मूलम्—

ऐं ह्रीं श्रीं घृणिस्सूर्य आदित्यों श्रीं ह्रीं ऐं ॥

No. 7616. स्कन्दमन्त्रः.
SKANDAMANTRAḤ.

Page, 1. Lines, 7 on a page.

Begins on fol. 29*a* of the MS. described under No. 5786.

Complete.

The repetition of this Mantra, which is addressed to Skanda or Subrahmaṇya, is considered to have the power to enable one to secure the favour of that god.

Beginning:

गुरुनमस्कारः । ओं रं (सं) स्कन्दाय नमः इति प्राणायामः १२ ।

* * * *

अस्य श्रीस्कन्दमन्त्रस्य कौशिक ऋषिः, गायत्री छन्दः, स्कन्दो देवता, स्कन्दप्रेरणया स्कन्दप्रीत्यर्थे जपे विनियोगः ।

End:

स्कन्दप्रेरणया स्कन्दप्रीत्यर्थं स्कन्दमहामन्त्रजपं करिष्ये ।
ओं (सं) स्कन्दाय नमः ओं इति जपः । उपसंहारः पूर्ववत् ॥

No. 7617. स्कन्दमन्त्रः.
SKANDAMANTRAḤ.

Pages, 2. Lines, 19 on a page.

Begins on fol. 45*a* of the MS. described under No. 2886, wherein this is found in the Ākāśabhairavakalpa 38*a* mentioned in the list of other works.

Complete.

Similar to the above.

The repetition of this Mantra is believed to have the power to enable one to win success in life.

Beginning:

स्कन्दस्य काश्यप ऋषिः, त्रिष्टुप्, सुब्रह्मण्यः, सां बीजं, स्रं श, विजयाय ।

End:

सूङ्कारं पूर्वमुच्चार्य सुब्रह्मण्याय तत्परम् ।
वह्निजायासमोपेतं मन्त्रुमष्टाक्षरं परम् ॥

Colophon:

इति षष्टितमोऽध्यायः ॥

No. **7618**. सुब्रह्मण्यकवचम्.

SUBRAHMAṆYAKAVACAM.

Pages, 4. Lines, 18 on a page.

Begins on fol. 306b of the MS. described under No. 5477, wherein it is found in the Mantramālikā (Ākāśabhairavakalpa) 273a.

Complete.

This Kavaca-mantra is addressed to Subrahmaṇya with a view to secure his protection Its repetition is considered to have the power of destroying one's sins, removing all kinds of diseases and troubles and of conferring prosperity on one.

Beginning:

अस्ति गुह्यं महापुण्यं सर्वप्राणिविधारकम् ।
जपमात्रेण पापघ्नं सर्वकामफलप्रदम् ॥
मुनीन्द्राणामिदं दैवं सर्वपीडानिवारकम् ।
स्कन्दस्य कवचं सेव्यं पठनाद्व्याधिनाशनम् ॥

* * * *

शिखां रक्षेत् कुमारश्च कार्त्तिकेयश्शिरस्तथा ।
ललाटं पार्वतीसूनुर्विशाखो भ्रूयुगं तथा ॥

End:

स्कन्दस्य कवचं नित्यं शृणुयादपि सर्वदा ।
सर्वभाग्यानि संप्राप्य शिवसायुज्यमाप्नुयात् ॥

Colophon:

इति सुब्रह्मण्यकवचं सम्पूर्णम् ॥

No. **7619.** सुब्रह्मण्यपञ्चदशाक्षरीमन्त्रः.

SUBRAHMAṆYAPAÑCADAŚĀKṢARĪMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 292a of the MS. described under No. 5477, wherein it is found in the Mantramālikā (Ākāśabhairavakalpa) 273a.

Complete.

This Mantra consists of 15 syllables and is addressed to Subrahmaṇya. The chief aim of this Mantra is to secure the protection of Brahmins.

Beginning:

अस्य श्रीसुब्रह्मण्यपञ्चदशाक्षरीमन्त्रस्य अमृताकर्षणदक्षिणामूर्तिः ऋषिः, गायत्री छन्दः, प्रसन्नस्कन्दो देवता, स्वां बीजं, ह्रीं शक्तिः, प्रसन्नस्कन्दप्रसादसिद्ध्यर्थे विनियोगः ।

End:

मन्त्रः—

ओं श्रीं क्लीं ह्रीं ऐं ई णं स्वां शरवणभव(य) इति पञ्चदशाक्षरोऽयं मन्त्रः विप्ररक्षाप्रधानः ॥

Colophon:

इति सुब्रह्मण्यपञ्चदशाक्षरी ॥

No. 7620. सुब्रह्मण्यमालामन्त्रः.

SUBRAHMAṆYAMĀLĀMANTRAḤ.

Pages, 4. Lines, 6 on a page.

Begins on fol. 23*a* of the MS. described under No. 2424, wherein it is given under the name of Subrahmaṇya-mantra.

Complete.

This Mantra is in praise of Subrahmaṇya under different significant names.

Beginning:

ओन्नमो भगवते अघोरसुब्रह्मण्याय महाबलपराक्रमाय क्रौञ्चगिरिमर्दनाय त्रयस्त्रिंशत्कोटिदेवताबन्धनाय ।

End:

शक्तिधराय शिखिवाहनाय कुमाराय कुङ्कुमवर्णाय कुक्कुटध्वजाय ओं फट् स्वाहा ॥

No. 7621. स्तेनवाग्बन्धनमन्त्रः.

STĒNAVĀGBANDHANAMANTRAḤ.

Page, 1. Lines, 22 on a page.

Begins on fol. 14*a* of the MS. described under No. 6045, wherein it is called Stēnavāgbandhanarājavaśikaraṇamantra.

Complete.

The repetition of this Mantra is considered to have the power to enable one to seal the mouth of thieves.

Beginning:

ఓం ముచ్చుగట్టుదు ముచ్చుఖేమదగట్టుదు నలుచ దరముచ్చు.

End:

ओं नमो भगवति शिष्टानुशिष्टे वा चामुण्डि स्वाहा ॥

No. 7622. स्फोटकीमन्त्रः.

SPHŌṬAKĪMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 14*a* of the MS. described under No. 5828.

Complete.

The repetition of this Mantra is intended to propitiate the presiding deity of small-pox and other such diseases.

Beginning:

अस्य श्रीमहास्फोटकीमन्त्रस्य कालमृत्युः ऋषिः, ज्वालामुखी जगती छन्दः, श्रीमहास्फोटकी देवता; हं बीजं, हुं शक्तिः, क्षीं कीलकं, मम महास्फोटकीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं ह्रीं शितवे शितवे स्वाहा । ओं रुद्र अष्टदुष्टमुष्टि भट् भट्रि ब्रह्म स्वाहा ॥

No. 7623. स्मरादिमातृकामन्त्रः.

SMARĀDIMĀTṚKĀMANTRAḤ.

Pages, 4. Lines, 16 on a page.

Begins on fol. 65*b* of the MS. described under No. 424.

Complete.

On the ceremonial touching of certain parts of the body while repeating the Mantra-formulas obtained by introducing the successive letters of the alphabet after **ऐं, ह्रीं, श्रीं, क्लीं.** The presiding deity of this Mantra is conceived to be the Mother of the Universe.

Beginning:

अस्य श्रीस्मरादिमातृकामन्त्रस्य संमोहन ऋषिः, गायत्री छन्दः, जगन्माता देवता, षड्दीर्घस्वरयुक्तेन स्मरेणाङ्गानि ।

End:

ऐं ह्रीं श्रीं क्लीं क्षं काममदनझषोन्मत्ताभ्यां नमः ।

एतैर्मातृकास्थानेषु र(व)र्णम् इक्षुचापपुष्पबाणधराः पद्मताम्बूलधारिणीभिश्शक्तिभिराश्लिष्टा ध्येयाः—इति कामरतिन्यासः ।

No. **7624.** स्वप्नवाराहीमन्त्रः.

SVAPNAVĀRĀHĪMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 35*a* of the MS. described under No. 5858.

Complete.

This Mantra is addressed to Svapnavārāhī who, as implied in her name, reveals, in dreams, past as well as future events.

Beginning:

अस्य श्रीस्वप्नवाराहीमहामन्त्रस्य सञ्जय ऋषिः, गायत्री छन्दः, वार्ताली देवता; ओं बीजं, ऐं शक्तिः, ग्लौं कीलकं, ममातीतानागतं चैव वदति स्वप्नरूपिणी । ओं ऐं ग्लौं वद वद वाराही विश्वमयी हुं फट् स्वाहा ।

End:

नमो ज्योतिर्मयी देवी ज्ञानविज्ञानरूपिणी ।
अतीतानागतं चैव वरदे(द मे) स्वप्नरूपिणी ॥

शुद्धोदकेन तर्पणं त्रिमधुयुक्तेन हवनम् ॥

No. 7625. स्वप्नवाराहीमन्त्रः.
SVAPNAVĀRĀHĪMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 1*b* of the MS. described under No. 5686.

Complete.

Similar to the above.

Beginning:

अस्य श्रीस्वप्नवाराहीमहामन्त्रस्य अग्निः ऋषिः, गायत्री छन्दः, श्रीस्वप्नवाराही देवता ; ह्रीं बीजं, स्वाहा शक्तिः, ओं कीलकं, मम श्रीस्वप्नवाराहीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

स्वप्ने शुभाशुभं भावि शंसन्ती भक्तकर्णयोः ।
दुःस्वप्नहारिणीं वन्दे वाराहीं स्वप्ननायिकाम् ॥

मूलम्—
ओं ह्रीं नमो वाराहि घोरे स्वप्नं ठ ठ स्वाहा ॥

No. 7626. स्वप्नवाराहीमन्त्रः.
SVAPNAVĀRĀHĪMANTRAḤ.

Pages, 2. Lines, 27 on a page.

Begins on fol. 233*b* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* mentioned in the list of other works

Complete.

Similar to the above.

Also held to be efficacious in causing the accomplishment of one's desires.

Beginning:

अस्य श्रीस्वप्नवाराहीमन्त्रस्य वामदेव ऋषिः, विराट् छन्दः, स्वप्नवाराही देवता ; ह्रीं बीजं, स्वाहा शक्तिः, प्रणवं कीलकं, ममेष्टकाम्यार्थे विनियोगः ।

End:

ओं ह्रीं नमो वाराहिके घोरे स्वप्नं वद स्वाहा।

* * * *

ततो जपं प्रकुर्वीत सहस्राष्टोत्तरं शुभम्।
पूर्वं तु कुम्भकं कृत्वा ततस्सिध्यति साधकः॥
स्वप्ने माणवकान् पश्यच्छुभाशुभनिदर्शनम्।
जपेत्संवत्सरं चैव सर्वज्ञत्वं च सिद्ध्येत्॥

No 7627. स्वप्नवाराहीमन्त्रः.

SVAPNAVĀRĀHĪMANTRAḤ.

Pages, 2. Lines, 10 on a page.

Begins on fol. 88*b* of the MS. described under No. 5566, wherein it is wrongly stated as beginning on fol. 88*a*. in the list of other works.

Complete.

Same as the above.

No. 7628. स्वप्नवाराहीमन्त्रः.

SVAPNAVĀRĀHĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 171*b* of the MS. described under No. 124.

Complete.

Similar to the above. Held also to have the power to enable one to defeat the aims of one's enemies.

Beginning:

ओं ह्रीं नमो वाराहि अघोरे स्वप्नं वद ठ ठ स्वाहा। अग्निः ऋषिः, गायत्री छन्दः, स्वप्नवाराही देवता, ह्रीं बीजं, स्वाहा शक्तिः, ऐं कीलकं, श्री—गः।

End:

ऐं ह्रीं नमो वाराहि अघोरे स्वप्नं ठ ठ ठ ठ स्वाहा।

ऐं ह्रीं श्रीं भञ्जि भाञ्जि महाभञ्जि मम वैरिमनः भग्नं कुरु कुरु अप्रीतिसन्नं कुरु हुं फट् स्वाहा ॥

No. 7629. स्वप्नहनूमन्मन्त्रः.

SVAPNAHANŪMANMANTRAḤ.

Page, 1. Lines, 6 on a page.

Begins on fol. 20*a* of the MS. described under No. 5864.

Complete.

This Mantra is addressed to Hanūmat ; and its repetition is considered to have the power to enable one to see things afar off, to hear sounds which are otherwise inaudible on account of distance, and to obtain knowledge of otherwise unknowable past, present and future events.

Beginning :

अस्य श्रीस्वप्नाख्यहनुमन्महामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीहनुमान् देवता ; ओं बीजं, स्वाहा शक्तिः, दूरदृष्टिरिति कीलकं, मम स्वप्नाख्यहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

ओं दूरदृष्टिदूरश्रवणसमागतानागतवर्तमानसर्वलोकवृत्तान्तविज्ञानं हनुमन्महीपं(द्यं) देहि देहि स्वाहा ॥

No. 7630. स्वर्णभैरवमन्त्रः.

SVARṆABHAIRAVAMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 292*a* of the MS. described under No. 5477, wherein it is found in the Mantramālikā (Ākāśabhairavakalpa) 273*a*, in the list of other works.

Complete.

This Mantra is addressed to Svarṇabhairava, *i.e.*, to Bhairava who bestows gold ; and its repetition is considered to have the power of removing one's poverty.

Beginning:

अस्य श्रीस्वर्णभैरवमन्त्रस्य दूर्वास ऋषिः, गायत्री छन्दः, स्वर्णभैरवो देवता, वं बीजं, ह्रीं शक्तिः, मम दारिद्र्यहरणार्थे विनियोगः।

End:

मन्त्रः—

ओं ह्रीं स्वर्णाकर्षणाय मम दारिद्र्यापहरणाय स्वाहा ॥

Colophon:

इति स्वर्णाकर्षणभैरवम् ॥

No. 7631. स्वर्णाकर्षणगणपतिमन्त्रः.

SVARṆĀKARṢAṆAGAṆAPATIMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 308*a* of the MS. described under No. 5477, wherein it is found in the Mantramālikā (Ākāśabhairavakalpa) 273*a*

Complete.

This Mantra is addressed to Gaṇapati; and its repetition is considered to have the power to confer on one all available gold.

Beginning:

अस्य श्रीस्वर्णाकर्षणगणपतिमन्त्रस्य गणक ऋषिः, नृचिद्गायत्री छन्दः, स्वर्णाकर्षणगणपतिर्देवता ; श्रां गां बीजं, श्रीं गीं शक्तिः, श्रं गूं कीलकं, मम स्वर्णाकर्षणगणपतिप्रसादसिद्ध्यर्थे विनियोगः।

End:

ओं ह्रीं श्रीं गं ह्रीं सं विरि विरि गणपत्यै वर वरद सर्वस्वर्णं मे वशमानय स्वाहा। लक्षं जपः। दशांशहोमः। इति ॥

No. 7632. स्वर्णाकर्षणदत्तात्रेयमन्त्रः.

SVARṆĀKARṢAṆADATTĀTRĒYAMANTRAḤ.

Pages, 1. Lines, 18 on a page.

Begins on fol. 308*b* of the MS. described under No. 5477, wherein it is found in the Mantramālikā (Ākāśabhairavakalpa) 273*a*.

Complete.

The repetition of this Mantra is intended to propitiate Dattātrēya and to enable one to become very wealthy.

Beginning:

अस्य श्रीस्वर्णाकर्षणदत्तात्रेयमन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः, ऋग्यजुस्सामाथर्वाणि छन्दांसि, स्वर्णाकर्षणदत्तात्रेयो देवता; श्रां द्रां बीजं, श्रीं द्रीं शक्तिः, श्रूं द्रूं कीलकं, स्वर्णाकर्षणदत्तात्रेयप्रसादसिद्ध्यर्थे विनियोगः ।

End:

ओं श्रां द्रां स्वर्णाकर्षणदत्तात्रेयाय नमः । लक्षजपम् । इति ॥

No. 7633. स्वर्णाकर्षणभैरवमन्त्रः.

SVARṆĀKARṢAṆABHAIRAVAMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 217*a* of the MS. described under No. 5661.

Complete.

Similar to what has been described under No. 7630

Beginning:

अस्य श्रीस्वर्णाकर्षणभैरवमहामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, स्वर्णाकर्षणभैरवो देवता; ह्रां बीजं, क्लीं शक्तिः, सः कीलकं, मम स्वर्णाकर्षणभैरवप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

अथ मनुः—

ओं ऐं क्लां क्लीं क्लूं ह्रां ह्रीं ह्रूं सः कुरु कुरु आपदुद्धारणाय अजामिलबद्धाय स्वर्णाकर्षणभैरवाय मम दारिद्र्यनिर्मूलकर्मठाय लोकेश्वराय

सानन्दाय श्रीमहाभैरवाय नमः। पुनर्न्यासध्यानं कुर्यात्। लमिति पञ्चपूजां कृत्वा॥

No. 7634. स्वर्णाकर्षणभैरवमन्त्रः.

SVARṆĀKARṢAṆABHAIRAVAMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 309a of the MS. described under No. 5477, wherein it is found in the Mantramālikā (Ākāśabhairavakalpa) 273a, in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीस्वर्णाकर्षणभैरवमन्त्रस्य दूर्वासभगवानृषिः, देवी गायत्री छन्दः, स्वर्णाकर्षणभैरवो देवता; ह्रां बीजं, स्वाहा शक्तिः, मम स्वर्णाकर्षणभैरवप्रसादसिद्ध्यर्थे विनियोगः।

End:

स्वर्णाकर्षणाय मम दारिद्र्यापहाराय ह्रां ह्रीं ह्रूं आं वं ओं स्वाहा दशसहस्रं जपः। दशांशहोमः। इति॥

No. 7635. स्वर्णाकर्षणभैरवमन्त्रः.

SVARṆĀKARṢAṆABHAIRAVAMANTRAḤ.

Pages, 3. Lines, 4 on a page.

Begins on fol. 33b of the MS. described under No. 5832, wherein it has been wrongly stated to begin on 34a, in the list of other works.

Complete.

Similar to the above.

Beginning:

एवङ्गुणवि– शुभतिथौ मम दुष्टारिष्टपरिहारार्थं . . . सर्वैश्वर्यप्राप्त्यर्थे जपे विनियोगः।

अस्य श्रीस्वर्णाकर्षणभैरवमहामन्त्रस्य ईश्वर ऋषिः, त्रिष्टुप् छन्दः, स्वर्णाकर्षणभैरवो देवता; ओं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, मम स्वर्णाकर्षणप्रसादासिद्ध्यर्थे जपे विनियोगः ।

End:

अजामिलबन्धनाय मम दारिद्र्यनिर्मूलनकर्मठाय स्वर्णभैरवाय स्वाहा । लमिति पञ्चपूजां समर्पयामि ॥

No 7636. स्वर्णाकर्षणभैरवमन्त्रः.

SVARṆĀKARṢAṆABHAIRAVAMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 46*a* of the MS. described under No. 5683.

Complete.

Similar to the above.

Beginning:

अस्य श्रीस्वर्णाकर्षणभैरवमन्त्रस्य महेश्वर ऋषिः, पङ्क्तिश्छन्दः, श्रीमहाभैरवो देवता; ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, यथोक्तफलसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं ऐं ह्रीं श्रीं ऐं ह्रीं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामिलबन्धनाय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्यविद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐं ॥

एवं ध्यात्वा महेशानि अयुतं प्रजपेन्मनुम् ।
दशांशं तर्पयेत्पश्चाद्धोमयेद्द्वादशांशतः ॥

No. 7637. स्वर्णाकर्षणभैरवमन्त्रः.

SVARṆĀKARṢAṆABHAIRAVAMANTRAḤ.

Pages, 3. Lines, 5 on a page.

Begins on fol. 81*b* of the MS. described under No. 1872, wherein read 81*b* for 81*a* against Svarṇākarṣaṇabhairavamantra in the list of other works.

Similar to the above.

Complete.

Beginning:

अस्य श्रीस्वर्णाकर्षणभैरवमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, स्वर्णाकर्षणभैरवो देवता; ह्रां बीजं, क्रूं शक्तिः, क्लीं कीलकं, स्वर्णाकर्षणभैरवप्रसादासिद्ध्यर्थे जपे विनियोगः।

End:

सर्वश्रीआकर्षणाय सर्वदंष्ट्रांशसाराय विषहराय सर्वक्षामाडम्बरविवर्जिताय ओं ह्रां ह्रीं कीलकं क्रों क्रीं क्रां हुं फट् स्वाहा॥

No. 7638. स्वर्णाकर्षणभैरवमन्त्रः.

SVARṆĀKARṢAṆABHAIRAVAMANTRAḤ.

Pages, 2. Lines, 21 on a page.

Begins on fol 29*a* of the MS. described under No. 2373, wherein this Mantra has been omitted to be included in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीस्वर्णाकर्षणभैरवमहामन्त्रस्य ईश्वर ऋषिः, पङ्क्तिश्छन्दः, स्वर्णाकर्षणभैरवो देवता; ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, स्वर्णाकर्षण(भैरव)प्रसादसिद्ध्यर्थे जपे विनियोगः।

End:

अजामिलबद्धाय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्यविद्वेषणाय महाभैरवाय नमः। इति दशसहस्रजपः। सिद्धिर्भवति॥

No. 7639. स्वर्णाकर्षणभैरवमन्त्रः.

SVARṆĀKARṢAṆABHAIRAVAMANTRAḤ.

Pages, 2. Lines, 19 on a page.

Begins on fol. 104*b* of the MS. described under No. 5568, wherein this Mantra has been omitted to be included in the list of other works.

Complete.

Similar to the above; also held to have the power to enable one to accomplish one's desires.

Beginning:

अस्य श्रीस्वर्णाकर्षणभैरवमहामन्त्रस्य दूर्वासभगवानृषिः, दैवी गायत्री छन्दः, स्वर्णाकर्षणभैरवो देवता, ह्रां बजिं, ह्रीं शक्तिः, ह्रूं स्वाहा कीलकं, मम सङ्कल्पसिद्ध्यर्थे जपे विनियोगः ।

End:

स्वर्णाकर्षणाय मम दारिद्र्यापहराय ह्रां ह्रीं ह्रूं आं वं वीं शीघ्रं स्वर्णाकर्षणं कुरु कुरु स्वाहा ॥

No. **7640.** स्वर्णाकर्षणभैरवमन्त्रः.

SVARṆĀKARṢAṆABHAIRAVAMANTRAḤ.

Pages, 2. Lines, 10 on a page.

Begins on fol. 204*b* of the MS. described under No. 124. wherein it is given as Svarṇākarṣaṇabhairavastōtra in the list of other works.

Complete.

Similar to the above; held also to be efficacious in driving off evil spirits.

Beginning:

स्वर्णाकर्षणभैरवस्य सुमनोर्ब्रह्मर्षिराख्यान्वितः
त्रिष्टुप् छन्द इतीरितं कनकहृच्छ्रीभैरवो देवता ।
ऐमित्यत्र च बीजमेव कथितं ह्रीं शक्तिरुक्तानघा
श्रीं कीलं च जपे नियोग इ . . . . . (हृद्भैर)वस्येष्टदे ॥

अस्य श्रीस्वर्णाकर्षणभैरवस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, त्रिष्टुप् छन्दः, श्रीस्वर्णाकर्षणभैरवो देवता; ऐं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, मम श्रीस्वर्णाकर्षणभैरवप्रसादसिद्ध्यर्थे . . . . . . सकल-भूतपिशाचब्रह्मराक्षसपातालाकाशग्रहोच्चाटनार्थे जपे विनियोगः ।

End:

मम दारिद्र्यविद्रावणाय ओं श्रीं महाभैरवाय नमः । होमविषये स्वाहा ॥

Colophon:

इति मन्त्रः ॥

No. **7641.** स्वर्णाकर्षणभैरवमन्त्रः.

SVARṆĀKARṢAṆABHAIRAVAMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 221*a* of the MS. described under No. 537.

Complete.

Similar to the above; also held to be efficacious in bringing about the accomplishment of the four Puruṣārthas or principal aims of life.

Beginning:

अस्य श्रीस्वर्णाकर्षणभैरवमन्त्रस्य सुपर्ण ऋषिः, इ(अ)तिजगती छन्दः, स्वर्णाकर्षणभैरवो देवता; ह्रीं बीजं, स्वाहा शक्तिः, हूं कीलकं, मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।

End:

सर्वजनवशीकरणाय सर्व(र्प)दंष्ट्रान्ध(न्त)काराय सर्वक्षामडा(माड)-म्बरविवर्जिताय ओं ह्रीं श्रीं क्लीं हूं फट् स्वाहा ॥

No. **7642.** स्वर्णाकर्षणभैरवमन्त्रः.

SVARṆĀKARṢAṆABHAIRAVAMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 204*b* of the MS. described under No. 124.

Complete.

Supposed to have the power to bring about a rain of gold.

Beginning:

स्वर्णाकर्षणभैरवमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीस्वर्णाकर्षणभैरवो देवता; ऐं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, मम स्वर्णाकर्षणभैरवप्रसादसिद्ध्यर्थे स्वर्णागमनसिद्ध्यर्थे जपे विनियोगः ।

End:

ओं नमः ओं श्रीस्वर्णाकर्षणभैरव एह्येहि मम स्वर्णवृष्टिं वर्षय काञ्चनाकर्षणभैरव परम . . . . रक्ष स्वाहा ॥

No. **7643.** स्वस्थानप्रदगोपालमन्त्रः.

SVASTHĀNAPRADAGŌPĀLAMANTRAḤ

Pages, 2. Lines. 5 on a page

Begins on fol. 53*b* of the MS. described under **No. 5885.**

Complete.

The repetition of this Mantra is intended to propitiate Kṛṣṇa conceived as the bestower of heavenly bliss.

Beginning:

अस्य श्रीस्वस्थानप्रदगोपालमन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, स्वस्थानप्रदगोपालो देवता, (श्रीं) बीजं, श्रः शक्तिः, स्वाहा कीलकं, स्वस्थानप्रदगोपालप्रीत्यर्थे जपे विनियोगः ।

End:

मनुः श्रीं कृष्णाय वासुदेवाय देवकीगर्भसंभूताय स्वाहा ॥

No. **7644.** हंसदक्षिणामूर्तिमन्त्रः.

HAṀSADAKṢIṆĀMŪRTIMANTRAḤ.

Page, 1. Lines. 18 on a page.

Begins on fol. 282*a* of the MS. described under **No. 5477,** wherein it is found in the Mantramālikā (**Ākāśabhairavakalpa**) **273*a*** in the list of other works.

Complete.

This Mantra is addressed to Dakṣiṇāmūrti or Śiva conceived as the Supreme Brahman; and its repetition is considered to be efficacious in bestowing wisdom and salvation.

Beginning:

अस्य श्रीहंसदक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, दक्षिणामूर्तिरुद्रो देवता; हं बीजं, सह(ः) शक्तिः, मम ज्ञानमोक्षार्थे विनियोगः ।

End:

मन्त्रः—ओं हं सः स्वाहा ॥

Colophon:

इति हंसदाक्षिणामूर्तिः ॥

No. **7645.** हंसदक्षिणामूर्तिमन्त्रः.

HAṀSADAKṢIṆĀMŪRTIMANTRAḤ.

Pages, 2. Lines, 18 on a page.

Begins on fol. 239*b* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* in the list of other works.

Complete.

Same as the above.

See under the previous number for the beginning.

End:

मन्त्रः—ओं हं सः ॥

No. **7646.** हंसदाक्षिणामूर्तिमन्त्रः.

HAṀSADAKṢIṆĀMŪRTIMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 25*b* of the MS. described under No. 5928.

Incomplete.

Same as the above.

No. **7647.** हंसदक्षिणामूर्तिमन्त्रः.

HAṀSADAKṢIṆĀMŪRTIMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 92*a* of MS. described under No. 5566, wherein it is apparently wrongly stated to begin on fol. 94 in the list of other works.

Complete.

Same as the above.

No. 7648. हंसमन्त्रः.
HAMSAMANTRAH.

Page, 1. Lines, 8 on a page.

Begins on fol. 10*b* of the MS. described under No. 5786.

Complete.

The repetition of this Mantra is intended to propitiate the Supreme Brahman.

Beginning:

ओं हं सस्सो हं इति प्राणायामः १२.

* * * *

अस्य श्रीषट्शतैकविंशत्स(तिस)हस्रश्वासरूपहंसमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, हंसो देवता, हंसप्रेरणया हंसप्रीत्यर्थे जपे विनियोगः ।

End:

ओं हं सः सो हं—इति जपः । उपसंहारः पूर्ववत् ॥

No. 7649. हंसमातृकान्यासः.
HAMSAMĀTṚKĀNYĀSAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 194*a* of the MS. described under No. 124, wherein it has been apparently omitted to be given in the list of other works.

Complete.

The Mantra-formulas here enjoined to be repeated during the ceremonial touching of certain parts of the body are first obtained by introducing the successive letters of the alphabet with the word नमः between हंसः and सोहं. Again the letters of the alphabet are taken from the end, and these together with the word नमः are placed between सोहं and हंसः. The nature of this arrangement of words forming the Mantra-formulas is indicated in the end extract.

Beginning :

अथ हंसमातृकान्यासः—

अस्य श्रीहंसयोरारोहद्वरोह(त)क्रममातृकान्यासस्य ब्रह्मा ऋषिः, गायत्री छन्दः, हंसस्वरूपिपरमात्मा देवता; हं बीजं, स शक्तिः, सो हं कीलकं, ममेष्टदेवताप्रीतये हंसमातृकान्यासः ।

End :

हंसः अं नमः सोहं—इति क्षान्तं न्यस्त्वा(स्य) सोहं क्षं नमः हंसः—इति आन्तं न्यसेत् ॥

Colophon :

इति हंसमातृकान्यासः ॥

No. **7650.** हंससप्ताक्षरमन्त्रः.

HAṀSASAPTĀKṢARAMANTRAḤ.

Pages, 2. Lines, 8 on a page.

Begins on fol. 10*b* of the MS. described under No. 5786.

Complete.

The repetition of this Mantra consisting of seven syllables is intended to propitiate Nārāyaṇa conceived in the form of a Haṁsa. The syllable Oṁ both in the beginning and the end is not to be taken as a part of the Mantra

Beginning :

ओं ओं हं सः सो हं इति प्राणायामः १२.

* * * *

अस्य श्रीसप्ताक्षरहंसमन्त्रस्य ब्रह्मा ऋषिः, उष्णिक् छन्दः, हंसरूपी नारायणो देवता, नारायणप्रेरणया नारायणप्रीत्यर्थे सप्ताक्षरहंसमन्त्रजपे विनियोगः ।

End :

ओं ओं हं सः सो हं स्वाहा ओं—इति जपः । उपसंहारः पूर्ववत् ॥

No. 7651. हंसाष्टाक्षरमन्त्रः.
HAṀ-ĀṢṬĀKṢARAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 11*a* of the MS. described under No. 5786.

Complete.

Similar to the above.

The Mantra-formula given here will be found to consist of eight syllables, if, as in the case of the Mantra described under the last number, the syllable Ōṁ both in the beginning and the end is left out of account

Beginning :

ओं ओं ह्रीं हं सः सो हं स्वाहा ओं इति प्राणायामः १२.

* * * *

अस्य श्रीअष्टाक्षरहंसमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, हंसरूपी श्रीनारायणो देवता, श्रीनारायणप्रेरणया श्रीनारायणप्रीत्यर्थे जपे विनियोगः ।

End :

अष्टाक्षरहंसमन्त्रजपङ्करिष्ये—

ओं ओं ह्रीं हं सः सो हं स्वाहा ओं—इति जपः । उपसंहारः पूर्ववत् ॥

No. 7652. हनूमत्कवचः.
HANŪMATKAVACAḤ

Pages, 3. Lines, 8 on a page.

Begins on fol. 50*b* of the MS. described under No. 5786.

Complete.

Addressed to Hanūmat for securing his favour and protection. The due repetition of this Mantra is considered to have the power to confer on the worshipper intelligence, strength, courage, fame, ability in speaking, health, worldly happiness and final salvation as well.

Beginning :

ध्यायेद्बालदिवाकरप्रतिनिभं(भं) देवारिदर्पापहं
देवेन्द्रप्रमुखप्रशस्तयशसं देदीप्यमानं रुचा ।
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥
हनूमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
पातु प्रतीच्यामक्षघ्नः पातु सागरतारकः ॥

End :

हनूमत्कवचं यस्तु पठेद्विद्वान् विचक्षणः ।
स एव पुरुषो लोके भुक्तिमुक्ती च विन्दति ॥

* * * *

बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता ।
अजाड्यं वाक्पटुत्वञ्च हनूमत्स्मरणाद्भवेत् ॥

No. **7653.** हनूमत्कवचः.
HANŪMATKAVACAḤ.

Pages, 2. Lines, 21 on a page.

Begins on fol. 18*a* of the MS. described under No. 2373.

Complete.

Similar to the above.

Held to be specially efficacious in wiping off sin and in counteracting the evils caused by various kinds of evil spirits as well as the evil effects of hostile Mantras and Tantras.

Beginning :

अस्य श्रीहनुमत्कवचस्तोत्रमन्त्रस्य श्रीरामचन्द्रभगवानृषिः, अनुष्टुप् छन्दः, श्रीहनूमान् देवता ; मारुतात्मज इति बीजं, अञ्जनासूनुरिति शक्तिः, वायुपुत्रेति कीलकं, श्रीहनुमत्प्रसादसिद्ध्यर्थे समस्तपापक्षयार्थे रोगकृत्यो(त्रि)मभूतप्रेतपिशाचब्रह्मराक्षसपरमन्त्रयन्त्रतन्त्रनिवारणार्थे जपे विनियोगः ।

End:

हनूमत्कवचं यस्तु पठेद्विद्वान् विचक्षणः ।
स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति ॥

No. **7654.** हनूमत्कवचः.

HANŪMATKAVACAḤ.

Pages, 11. Lines, 5 on a page.

Begins on fol. 32*a* of the MS. described under No. 5953.

Complete as found in the Brahmāṇḍapurāṇa.

Similar to the above.

Beginning:

अस्य श्रीहनुमत्कवचस्तोत्रमन्त्रस्य रामचन्द्रभगवानृषिः, अनुष्टुप् छन्दः, श्रीरामचन्द्रो देवता; अञ्जनासूनुरिति बीजं, मारुतात्मज इति शक्तिः, मम शान्तिद्वाराणीति कीलकं, मम सकलदुरितनिवारणसमस्त-पापक्षयार्थं हनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

वन्दे विद्वज्जलधिमरुनं [स]ब्रह्मसूत्रं गरिष्ठं
कर्णद्वन्द्वे कनकरुचिरे कुण्डले धारयन्तम् ।
सत्कौपीनं कपिवरवरं कामरूपं कपीन्द्रं
पुत्रं वायोरुणेन्द्रं स्मितशुकं (दधितरणे) वज्रदेहं वरिष्ठम् ॥

Colophon:

इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीरामप्रोक्तं हनुमत्कवचं संपूर्णम् ॥

No. **7655.** हनूमत्कवचः.

HANŪMATKAVACAḤ.

Pages, 6. Lines, 6 on a page.

Begins on fol. 32*a* of the MS. described under No. 2424.

Complete.

Similar to the above.

Beginning:

अस्य श्रीहनुमत्कवचस्तोत्रमहामन्त्रस्य शङ्कर ऋषिः, अनुष्टुप् छन्दः, श्रीहनुमान् देवता ; पवनात्मज इति बीजं, अञ्जनासूनुरिति शक्तिः, वायुपुत्र इति कीलकं, श्रीहनुमत्प्रसादसिद्ध्यर्थं मम शरीरसंरक्षणार्थे जपे विनियोगः ।

End:

स पुमान् श्रियमाप्नोति सर्वत्र विजयी भवेत् ।
यः पठेद्धारयन्नित्यं सर्वान् कामानवाप्नुयात् ॥

No. **7656.** हनूमत्कवचः.
HANŪMATKAVACAḤ.

Pages, 3. Lines, 9 on a page.

Begins on fol. 67*a* of the MS. described under No. 21.

Complete.

Similar to the above

Beginning:

अस्य श्रीहनुमत्कवचस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः, अनुष्टुप् छन्दः; श्रीहनूमान् देवता; मारुतात्मज इति बीजं, अञ्जनासूनुरिति शक्तिः, वायुपुत्रेति कीलकं, मम हनुमत्प्र —योगः । . . .

हनुमान् पूर्वतः पातु दक्षिणं पवनात्मजः ।
पातु प्रतीचीं रक्षोघ्नः पातु सागरतारकः ॥

End:

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥

No. **7657.** हनूमत्कवचः.
HANŪMATKAVACAḤ.

Pages, 4. Lines, 5 on a page.

Begins on fol. 7*b* of the MS. described under No 5864.

This Mantra like the one described under No. 7654 is taken from the Brahmāṇḍapurāṇa.

Complete.

Similar to the above.

Beginning :

अस्य श्रीहनुमत्कवचस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः, गायत्री छन्दः, श्रीहनुमान् रुद्रो देवता ; मारुतात्मज ह्रामित्यादिकरहृदयादि न्यासौ कृत्वा . . . .

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
पातु प्रतीचीमक्षघ्नः पातु सागरतारकः ॥

End :

यो वारां निधिमल्पपल्वलमिवालङ्घ्य प्रतापान्वितः
वैदेहीघनशोकतापहरणो वैकुण्ठभक्तप्रियः ।
अक्षाद्यार्चितराक्षसेश्वरमहादर्पापहारी रणे
सोऽयं वानरपुङ्गवोऽवतु सदा चास्मान् समीरात्मजः ॥

Colophon :

इति श्रीब्रह्माण्डपुराणे श्रीहनुमत्कवचस्तोत्रं संपूर्णम् ॥

No. **7658.** हनूमत्कवचः.
HANŪMATKAVACAḤ.

Pages, 10. Lines, 5 on a page.

Begins on fol. 19*a* of the MS. described under No. 6393.

Complete.

Same Mantra as the above.

No. **7659.** हनूमत्कवचः.
HANŪMATKAVACAḤ.

Pages, 5. Lines, 6 on a page.

Begins on fol. 92*a* of the MS. described under No. 2549.

Complete.

Same as the above.

Colophon :

श्रीहनुमत्कवचं संपूर्णम् ॥

No. **7660.** हनूमत्कवचः.

HANŪMATKAVACAḤ

Pages, 5. Lines, 7 on a page.

Begins on fol. 20*b* of the MS described under No. 5788.

Complete.

Same Mantra as the above.

Colophon:

इति श्रीहनूमत्कवचं संपूर्णम् ॥

No. **7661.** हनूमत्कवचः.

HANŪMATKAVACAḤ.

Pages, 7. Lines, 5 on a page.

Begins on fol. 5*b* of the MS. described under No. 6151, wherein it is wrongly given as beginning on 5*a*.

Complete.

Similar to the above.

See under the previous number for the beginning

End:

सोऽयं वानरपुङ्गवोऽवतु सदा चास्मान् समीरात्मजः ॥
हनूमानञ्जनासूनुर्वायुपुत्रो महाबलः ।
रामेष्टः फल्गुनसखः पिङ्गाक्षोऽमितविग्रहः ॥

* * * *

जले रक्षतु वाराहस्स्थले रक्षतु वामनः ।
अव्याच्च नारसिंहस्तु सर्वतः पातु केशवः ॥

Colophon:

श्रीहनूमत्कवचं संपूर्णम् ॥

No. **7662.** हनूमत्कवचः.

HANŪMATKAVACAḤ.

Pages, 8. Lines, 5 on a page.

Begins on fol. 53*a* of the MS. described under No. 6152.

Complete as found in the Brahmāṇḍapurāṇa.

Similar to the above.

This Mantra is believed to have the power to enable one to secure the favour of Rāma.

Beginning:

अस्य श्रीहनूमत्कवचस्तोत्रमन्त्रस्य अनुष्टुप् छन्दः, श्रीरामचन्द्रो [देवता] भगवानृषिः, हनूमान् देवता; मारुतात्मज इति बीजं, अञ्जनासूनुरिति शक्तिः, वायुपुत्र इति कीलकं, श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

* * * *

हनूमान् पूर्वतः पातु केसरिप्रियनन्दनः ।
अधस्ताद्विष्णुभक्तस्तु पातु मध्यं च पावनः ॥

End:

चन्द्राभं चरणारविन्दयुगलं(लीं)कौपीनमौञ्जीधरं
बालं शोणदुकूल(दिव्य)वसनं यज्ञोपवीताजिनम् ।
हस्ताभ्यामवलम्बिताञ्जलिपुटं हारावलीमण्डितं
पश्चाल्लम्बिशिखं प्रसन्नवदनं श्रीवायुपुत्रं भजे ॥

Colophon:

इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे हनूमत्कवचस्तोत्रं सम्पूर्णम् ॥

No. 7663. हनूमत्पञ्चदशाक्षरमन्त्रः.

HANŪMATPAÑCADAŚĀKṢARAMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 19*a* of the MS. described under No. 5864, wherein it is wrongly given as Hanūmatpañcākṣarīmantra in the list of other works.

Complete.

This Mantra consists of 15 syllables and is addressed to Hanumat. Its repetition is held to be efficacious in causing the destruction of one's enemies.

Beginning :

अस्य श्रीहनूमत्पञ्चदशाक्षरीमहामन्त्रस्य अमृतविराट् छन्दः, ईश्वर ऋषिः, श्रीपञ्चवक्त्रहनूमान् देवता; हं बीजं, स्वाहा शक्तिः, ग्लौं फट् कीलकं, शत्रुसंहरणार्थे जपे विनियोगः ।

End :

ओं हं अरिमर्दनमर्कटाय ग्लौं फट् स्वाहा ॥
मैत्रेयनीलकपिलध्वजदत्तगाल-
मैन्दाङ्गदाश्वविजयं(यान्) भरतं सुषेणम् ।
हरिशात्मकस्य (र्यर्कसूनु) वसुपुष्करसोमदत्तान्
पुण्यान् स्मरामि हनुमत्पदपद्मभक्तान् ॥

No. **7664.** हनूमदापदुद्धारणस्तोत्रमन्त्रः.

HANŪMADĀPADUDDHĀRAṆASTŌTRAMANTRAḤ.

Page, 2. Lines, 18 on a page.

Begins on fol. **21***a* of the MS. described under No. **2886.**

Complete.

This Mantra which is in praise of Hanumat is considered to be efficacious in saving one from dangers.

Beginning :

अस्य श्रीहनुमदापदुद्धार[णादुद्धार]णस्तोत्रमहामन्त्रस्य विभीषण ऋषिः, अनुष्टुप् छन्दः, श्रीहनुमान् देवता, श्रीहनुमत्प्रीत्यर्थे जपे विनियोगः ।

End :

नमो राघवदूताय सीताशोकविनाशिने ।
आञ्जनेयाय हरये लङ्कालङ्कारहारिणे ॥

No. **7665.** हनूमद्गारुडमन्त्रः.

HANŪMADGĀRUḌAMANTRAḤ.

Page, 1. Lines, 28 on a page.

Begins on fol. 245*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 22 *a* in the list of other works.

Incomplete.

In this Mantra, Hanumat is conceived as possessing the powers of Garuḍa in removing the effects of poisons.

Beginning :

ओं भूर्भुवस्सुवरोम्. . . . .

ओं नमो भगवते हनुमत ग्रहमण्डलभूतमण्डलपिशाचमण्डल ।

End :

महानागकुलविषनिर्विष झटिति खे खे पवनपुत्र वैश्वानर . .

* * * *

भजास्पुरके स्पुरके स्वाहा ॥

Colophon :

इति हनुमद्गारुडमन्त्रः ॥

No. 7666. हनूमद्दिग्बन्धनमन्त्रः.

HANŪMADDIGBANDHANAMANTRAḤ.

Page, 1. Lines, 7 on a page.

Begins on fol 45a of the MS. described under No. 235, wherein it has been apparently omitted to be included in the list of other works.

Complete.

The repetition of this Mantra addressed to Hanumat is supposed to have the power to cast a magic spell over all the quarters to enable the repeater to safeguard himself from all possible dangers that may come therefrom.

Beginning :

ओं ह्रीं श्रीरामदूत प्रतापहनुमन् ओं लं इन्द्रदिशं बन्ध बन्ध, ओं ह्रीं श्रीरामदूत वीरहनुमन् ओं रं अग्निदिशं बन्ध बन्ध ।

End:

यं रं लं वं शं षं सं हं ळं क्षं दश दिशः बन्ध बन्ध पैकाय भूर्भुवस्सुवरों ॥

Colophon:

इति दिग्बन्धः ॥

No. **7667.** हनूमद्द्वादशाक्षरमन्त्रः.

HANŪMADDVĀDAŚĀKṢARAMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 238*b* of the MS. described under No. 5177.

Complete.

The repetition of this Mantra consisting of 12 syllables is intended to propitiate Hanumat. The word Oṁ is not to be taken into account in counting the syllables.

Beginning:

अस्य श्रीहनुमद्द्वादशाक्षरीमन्त्रस्य श्रीरामचन्द्रभगवानृषिः, गायत्री छन्दः, श्रीहनुमान् देवता; यं बीजं, स्वाहा शक्तिः, हनुमत्प्रसादसिद्ध्यर्थे विनियोगः ।

End:

मन्त्रः—

ओं यं वायुपुत्राय पिङ्ग[ल]ाक्षाय स्वाहा ॥

Colophon:

इति द्वादशाक्षरी हनुमद्द्वादशाक्षरी ॥

No. **7668.** हनूमद्द्वादशाक्षरमन्त्रः.

HANŪMADDVĀDAŚĀKṢARAMANTRAḤ.

Pages, 2. Lines, 28 on a page.

Begins on fol. 244*b* of the MS. described under No. 581, wherein it is found in the **Mantramālikā** 229*a* in the list of other works

Complete.

Same as the above.

No. 7669. हनूमद्द्वादशाक्षरमन्त्रः.

HANŪMADDVĀDAŚĀKṢARAMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 95*a* of the MS. described under No. 5566, wherein it has been wrongly noted as beginning on fol. 99 in the list of other works.

Complete.

Same as the above.

No. 7670. हनूमद्बडबानलमन्त्रः.

HANŪMADBAḌABĀNALAMANTRAḤ.

Pages, 3. Lines, 6 on a page.

Begins on fol. 215*a* of the MS. described under No. 7247.

Complete.

This Mantra is addressed to Hanumat conceived to be as terrible as the submarine fire known as Baḍabānala; and its repetition is considered to have the power to enable one to secure the favour of Rāma.

Beginning:

अस्य श्रीहनूमद्बडबानलमहामन्त्रस्य अनुष्टुप् छन्दः, श्रीहनुमान् देवता, श्रीमुख्यप्राणान्तर्यामिश्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

* * * *

ओं नमो भगवते श्रीहनूमते प्रकटपराक्रमाक्रान्ताय सकलदिग्बन्धनसेविताशाधवलीकृतहार वज्रदेह ।

End:

ओं नमो भगवते श्रीवीररौद्रहनूमते ज्वलितपिङ्गलनेत्राय शाकिनीडाकिनीभूतप्रेतपिशाचयक्षराक्षसपरमन्त्रपरयन्त्रपरतन्त्रविच्छेदन मम ह्रां ह्रीं रिं ह्रुं रुं फट् स्वाहा ॥

Colophon:

हनुमत्कवचं(द्बडबानलः)संपूर्णः ॥

No. **7671.** हनूमन्मन्त्रः.

HANŪMANMANTRAḤ.

Pages, 4. Lines, 6 on a page.

Begins on fol. 219*a* of the MS. described under No. 7247.

Complete.

The repetition of this Mantra is believed to have the power to propitiate Hanumat.

Beginning:

अस्य श्रीपञ्चवक्त्रहनुमन्महामन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, श्रीहनुमान् देवता ; मारुतात्मज इति बीजं, अञ्जनासूनुरिति शक्तिः, वायुपुत्र इति कीलकं, श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥

No. **7672.** हनूमन्मन्त्रः.

HANŪMANMANTRAḤ.

Pages, 2. Lines, 16 on a page.

Begins on fol. 206*a* of the MS. described under No. 424, wherein it has been apparently omitted to be included in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीहनूमन्महामन्त्रस्य शौनक ऋषिः, जगती छन्दः, श्रीहनुमन्त्र(न्म)हामन्त्रो देवता ; रं बीजं, फट् शक्तिः, हं कीलकं, आञ्जनेयप्रीत्यर्थे जपे विनियोगः ।

End:

ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहं
देवेन्द्रप्रमुखप्रशस्तयशसं देदीप्यमानं मृतां(थे) ।

सुग्रीवादिसमस्तवानरयुतं सूर्योक्तितत्त्वाप्रियं
संरक्तायतलोचनं पवनजं पीताम्बरालङ्कृतम् ॥

No. **7673.** हनूमन्मन्त्रः.
HANŪMANMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 288*a* of the MS. described under No. 5477.

Complete.

Similar to the above.

Beginning:

अस्य श्रीहनुमन्मन्त्रस्य श्रीरामचन्द्रभगवानृषिः, अनुष्टुप् छन्दः, श्रीहनुमान् देवता; हं बीजं, स्वाहा शक्तिः, हनुमत्प्रसादसिद्ध्यर्थे विनियोगः ।

End:

मन्त्रः—

ओं रामदूताय स्वाहा ॥

Colophon:

इति हनु(मन्)मन्त्रः ॥

No. **7674.** हनूमन्मन्त्रः.
HANŪMANMANTRAḤ.

Page, 1. Lines, 28 on a page.

Begins on fol. 244*b* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* in the list of other works.

Complete.

The Mantra here is the same as in the work described under the previous number; but there is a very slight difference in the preliminary details mentioned in relation to the repetition of this Mantra.

Beginning :

अस्य श्रीहनुमन्[त]मन्त्रस्य श्रीरामचन्द्रभगवानृषिः, अनुष्टुप् छन्दः, श्रीहनुमान् देवता; ओं बीजं, स्वाहा शक्तिः, हनुमत्प्रसादसिद्ध्यर्थे विनियोगः ।

End :

मन्त्रः—

ओं रामदूताय स्वाहा ॥

No. **7675.** हनूमन्मन्त्रः.

HANŪMANMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 95*a* of the MS. described under No. 5566, wherein it is wrongly stated as beginning on fol. 99 in the list of other works.

Complete.

Same as the above.

No. **7676.** हनूमन्मन्त्रः.

HANŪMANMANTRAḤ.

Pages, 4. Lines, 6 on a page.

Begins on fol. 21*b* of the MS. described under No. 7247, wherein it is given as Pañcavaktrahanūmatstōtramantra in the list of other works.

Complete.

This Mantra is addressed to Hanūmat conceived as having five faces; and its repetition is considered to be efficacious in destroying evil spirits and in counteracting the evil effects of hostile Mantras and Tantras.

Beginning :

अस्य श्रीपञ्चवक्त्रहनुमत्स्तोत्रमन्त्रस्य ईश्वर ऋषिः, देवी गायत्री छन्दः, पञ्चमुखि(ख)रौद्रिं(द्र) ओं श्रीपरमात्मा देवता; ओं ह्रूं बीजं, ओं ह्रीं शक्तिः, ओं ह्रैं कीलकं, मम पञ्चमुखहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

सर्वभूतप्रेतपिशाचयक्षराक्षसकूश्माण्डविनायकभैरवादिमहाभूतमहापर - मन्त्रयन्त्रतन्त्ररोगदुष्टमृगभुजङ्गवृश्चिकादि विनाशय ओं ओं कुरु करु फट् स्वाहा ॥

No. 7677. हनूमन्मन्त्रः.
HANŪMANMANTRAḤ.

Pages, 6. Lines, 7 on a page.

Begins on fol. 13*a* of the MS. described under No. 5819.

Complete.

Similar to the above.

Held also to be efficacious in causing disturbance in the enemy's army and in enabling one to accomplish one's desires.

Beginning:

अस्य श्रीहनुमन्मन्त्रस्य अगस्त्य ऋषिः, देवी गायत्री छन्दः, हनुमान् देवता; हकारो बीजं, स्वाहा शक्तिः, हनुमत्प्रीत्यर्थे विनियोगः ।

End:

हर हर परबलं क्षोभय मम क्षोभय मम सर्वकार्याणि साधय साधय हुं फट् स्वाहा ॥

No. 7678. हनूमन्मालामन्त्रः.
HANŪMANMĀLĀMANTRAḤ.

Pages, 4. Lines, 6 on a page.

Begins on fol. 1*a* of the MS. described under No. 6393, wherein it is given as Hanūmanmantra in the list of other works.

Complete.

This Mantra also is in praise of Hanūmat under different significant names; and its repetition is considered to be efficacious in sealing the mouths of bad people, in removing fears arising from kings and thieves, in freeing one from enchained bondage, in counteracting the evil effects of hostile Mantras and Tantras, and in accomplishing desired objects.

Beginning:

ओं नमो भगवते प्रकटपराक्रमाय आक्रान्तसकलदिङ्महीमण्डलाय यशोवितानधवलीकृतजगत्रितयाय वज्रदेहरुद्रावतार लङ्कापुरीदहन उद्धिबन्धन दशग्रीवकृतान्त ।

End:

सर्वदुष्टजनमुखबन्धनं कुरु राजचोरभयं प्रशमय शृङ्खलाबन्धनं मोचय परमन्त्रयन्त्रतन्त्राणि नाशय स्वमन्त्रयन्त्रतन्त्राणि सुरक्षय सर्वाभीष्टं कुरु कुरु असाध्यं साधय हुं फट् स्वाहा ॥

Colophon:

श्रीआञ्जनेय(माला)मन्त्रः संपूर्णः ॥

No. **7679.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 240*b* of the MS. described under No. 7247.

Complete.

Similar to the above.

Beginning:

ओं नमो भगवते श्रीहनुमते प्रकटपराक्रमाक्रान्तसकलदिङ्मण्डलाय ।

End:

स्वमन्त्रयन्त्रविद्याप्रकटनाय सर्वारिष्टशमनाय सर्वशत्रुविनाशनाय असाध्यसाधनाय ओं ह्रां ह्रीं ह्रूं हुं फट् स्वाहा ॥

No. **7680.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 4. Lines, 6 on a page.

Begins on fol. 29*a* of the MS. described under No. 5737.

Complete.

Similar to the above.

Beginning:

ओं नमो भगवते पञ्चवक्त्रहनुमते प्रकटितबलपराक्रमाक्रान्तसकल-दिङ्मण्डलाय निजकीर्तिस्फूर्तिधावनापनीयमानजगत्त्रितयाय अतुलबलैश्वर्य-रुद्रावताराय महारावणमद्वारणगर्वनिर्वापणोत्कण्ठकण्ठीरवाय ब्रह्मास्त्रगर्व-सर्वङ्कषवज्रशरीराय ।

End:

ओं नमो भगवते पञ्चवक्त्रहनूमते ओं व्रौं क्ष्रां क्ष्रीं हुं ह्रौं ग्लां ग्लां श्रीं क्लीं क्लीं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः हुं फट् खे खे हुं फट् स्वा-हें(हों) विं क्लीं स्वाहा ॥

Colophon:

इति पञ्चवक्त्रहनुमन्मालामन्त्रः समाप्तः ॥

No. **7681.** हनूमन्मालामन्त्रः.
HANŪMANMĀLĀMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 12*a* of the MS. described under No. 5828, wherein it is given as Hanūmadviṣaya in the list of other works.

Complete.

Similar to the above. Held to be efficacious in removing various kinds of dire diseases.

Beginning:

ओं नमो भगवते रुद्राय ज्वलितपिङ्गललोचनाय ऐकाहिकद्व्याहि-कत्र्याहिकचातुर्थिकज्वरनाशनाय भूतनाशनाय हुं फट् स्वाहा । ओं नमो भगवते रुद्राय ज्योतिःपिङ्गललोचनाय अञ्जनानन्दनाय ।

End:

भूतज्वरविषमज्वरविष्णुज्वरमहेश्वरज्वरस्फोटकशिरोवेधकुक्षिशूलाङ्गशू-लगुल्मशूलक्रूरनागसर्वविधशूलैर्विष . . . . छिन्धि छिन्धि उच्चाटय हुं फट् स्वाहा ॥

No. **7682.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 243*a* of the MS. described under No. 7247.

Incomplete.

Similar to the above.

अस्य श्रीहनुमन्मालामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, वायुपुत्रहनुमान् देवता; हं बीजं, सः शक्तिः, ह्रां कीलकं, हंसमूर्तये शिरसे स्वाहा, वायुसुताय शिखायै वौषट्, ओं श्रीरामदूताय कवचाय हुं, अग्निगर्भाय नेत्रत्रयायै(य)वौषट्, ओं ब्रह्मास्त्रनिवारणाय ह(अ)स्त्रायभु(फ)ट्।

* * * *

ओं नमो भगवते श्रि(त)जगत्रितयाय वज्रदेहरुद्रावताराय[।]

End:

भूतज्वर - प्रेतज्वर - महाज्वरज्वर --शि(शी)तज्वर - ऐकाहिकज्वर-- द्व्याहिकज्वर - त्र्याहिकज्वर - चातुर्थिकज्वर - विषमज्वर - महेश्वरज्वर - वैष्णवज्वर - सर्वज्वरान् छिन्द्धि छिन्द्धि यक्षब्रह्मराक्षसबेताल.

No. **7683.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 3. Lines, 8 on a page.

Begins on fol. 1*a* of the MS. described under No. 6546, wherein it is wrongly given as Hanūmanmantrakalpa 1*a*, in the list of other works.

Complete; forms the second Adhyāya of the Sudarśanasaṁhitā.

Similar to the above.

Beginning:

अस्य श्रीहनुमन्मालाष्टाक्षरमन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, कालाग्निरुद्रश्रीहनुमान् देवता; ओं बीजं, ह्रीं शक्तिः, अरिसंहारेति कीलकं, श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे होमे पारायणे विनियोगः।

End :

लङ्कापुरीदहनाय सीतासमाश्वास(नाय)महेश्वरज्वरऐकाहिकद्व्याहिकत्र्याहिकचातुर्थिकज्वरसर्वभूतरक्षमहानागकुल फट् फट् फट् स्वाहा ॥

ध्यानम्—

निमील्य नयने सम्यक् करौ चोग्रशिरस्ततः ।

* * * *

कुण्डलद्वयसंशोभिमुखाम्भोजं हरिं भजे ॥

Colophon :

इति श्रीसुदर्शनसंहितायामाञ्जनेयाष्टाक्षरीमालामन्त्रविधानं नाम द्वितीयोऽध्यायः ॥

No. **7684.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 8. Lines, 5 on a page.

Begins on fol. 1*a* of the MS. described under No. 3862, wherein it is wrongly given as Hanūmatkavaca in the list of other works.

Incomplete.

Similar to the above.

Held to be efficacious in driving off evil spirits, in the curing of various kinds of diseases, and in effecting the accomplishment of one's desires.

Beginning :

ओं एवङ्गुणविशेषणविशिष्टायां शुभतिथौ भूतप्रेतपिशाचोच्चाटनार्थं वातपैत्त्यश्लेष्मादिसर्वरोगनिवारणार्थं. . . . .

अस्य श्रीहनुमन्महा[न्]मालामन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः श्रीअघोरविश्वरूपश्रीहनुमान् देवता ; ह्रीं बीजं; स्वाहा शक्तिः, हुं कीलकं, असावेदिति कवचं ; ममेष्टकाम्यार्थसिद्ध्यर्थे जपे विनियोगः ।

End :

स्वमन्त्र स्वतन्त्र स्वयन्त्र सर्वप्रघट्टकाय सर्वारिष्टविनाशनाय असाध्यसाधनाय शृङ्खलाबन्धविमोचनाय मम.

No. **7685.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 4. Lines, 26 on a page.

Begins on fol. 62*b* of the MS. described under No. 446.

Complete.

Similar to the above.

Beginning:

अस्य श्रीहनुमन्मालामन्त्रस्य शौनक ऋषिः, अतिजगती छन्दः, श्रीहनुमान् रुद्रो देवता, रं बीजं, फट् शक्तिः, मां कीलकं, मम श्रीहनुमन्मालामन्त्रप्रसादसिध्यर्थे विषज्वररोगभूतसंभाषणसर्वदेवतावेशशाकिनीडाकिनीवेतालसमूहब्रह्मराक्षससर्वग्रहोच्चाटनार्थे जपे विनियोगः ।

End:

श्रीरामचन्द्रमनोऽभिलषिताय लङ्कापुरीदहनकारणाय ओं यं रं खैं ओं नमो भगवते श्रीरामदूताय हुं फट् स्वाहा ॥

No. **7686.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 8. Lines, 8 on a page.

Begins on fol. 31*a* of the MS. described under No. 5788.

Complete.

Similar to the above.

Beginning:

अस्य श्रीहनुमन्मालामहामन्त्रस्य शौनक ऋषिः, अतिजगती छन्दः, श्रीहनुमान् रुद्रः परमात्मा देवता; हं बीजं, फट् शक्तिः, हुं कीलकं, मम विषग्रहरोगभूतसंभाषणसर्वदेवताशाकिनीडाकिनीसर्वग्रहोच्चाटनार्थे जपे विनियोगः ।

End:

ओं तं यं ईं शां नमो भगवते श्रीरामदूतहनूमते हुं फट् स्वाहा ॥

Colophon:

इति शौनकसंहितायां रोगकृत्रिमभूतोचा(च्चा)टनहनुमन्मालामहामन्त्रः संपूर्णः ॥

No. 7687. हनूमन्मालामन्त्रः.
HANŪMANMĀLĀMANTRAḤ.

Pages, 5. Lines, 6 on a page.

Begins on fol. 17*a* of the MS. described under No. 6005.

Complete.

Similar to the above.

It is stated in the end that, if this Mautra is repeated seven times every day, it will confer prosperity on one; and, if repeated on Sundays it will enable one to accomplish one's desires.

Beginning:

अस्य श्रीपञ्चमुखवीरहनुमत्कवचस्तोत्र(न्माला)मन्त्रस्य रामचन्द्र ऋषिः, अनुष्टुप् छन्दः, श्रीसीतारामो देवता; सकललोकोपकारसिद्ध्यर्थे हनुमत्कवचमन्त्रजपे विनियोगः। . . . .
पिङ्गलनयनाय अमितविक्रमाय सूर्यबिम्बालम्बोष्ठानिलालङ्कृताय अगम्यमहःकपिलाय।

End:

सप्तवारं पठेन्नित्यं स[कल](र्व)सौभाग्यदायकम्।
भानुवारे पठेन्नित्यमिष्टकाम्यार्थसिद्धये॥

No. 7688. हनूमन्मालामन्त्रः.
HANŪMANMĀLĀMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 27*a* of the MS. described under No. 6005.

Complete.

Similar to the above.

See under the previous number for the beginning.

End:

ओं हरिमर्कट मर्कट मर्कट वं वं वं वं वं फट् फट् स्वाहा॥

No. **7689.** हनूमन्मालामन्त्रः.
HANŪMANMĀLĀMANTRAḤ.

Page, 1. Lines, 19 on a page

Begins on fol. 24*a* of the MS described under No. 2886.

Complete.

Similar to the above. The concluding stanzas describe well the value and efficacy of this Mantra.

Beginning :

प्रकटपराक्रमाक्रान्तबलोपेतसर्वदिङ्मण्डल यशोवितानधवलीकृतजगत्त्रितय वज्रदेह रुद्रावतार लङ्कापुरीदहन उदधिलङ्घन ।

End :

परमन्त्रपरयन्त्रपरतन्त्रान् छेदय स्वविद्यां प्रकटय मां रक्ष श्रीरामदूताय हुं फट् स्वाहा ॥

* * * *

मालामन्त्रं समालिख्य भूतानि त्रासय द्वि च ।
खे गृह्णन् गृह्णन् स्वाहा पश्चान्नेत्राक्षरं लिखेत् ॥
दिक्पालश्च बहिर्लेख्यं (ख्यो) हनुमद्यन्त्रमुत्तमम् ।
सर्वमृत्युप्रशमनं सर्वसौभाग्यदायकम् ॥
सर्वसिद्धिप्रदं लोके दुष्टग्रहनिवारणम् ।
नेत्राक्षरं य र ल व श ष स ह ॥

No. **7690.** हनूमन्मालामन्त्रः.
HANŪMANMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 239*b* of the MS. described under No. 7247.

Complete.

Held to have the power to propitiate Hanūmat.

Beginning :

श्रीहनुमन्मालामन्त्रः--

अस्य श्रीविरमा(वीरहनुमन्)महामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, हनुमान् महादेवता ; ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, मम हनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

शरणागतवज्रपञ्जराय हूं लं गं हूं रं यं खे खे हुं फट् स्वाहा ॥

No. **7691.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 5. Lines, 5 on a page.

Begins on fol. 115*a* of the MS. described under No. 6685, wherein it has been omitted to be included in the list of other works. The Hanūmatkalpa given therein in the list of other works begins on fol. 117*a* and not on fol. 115*a*.

Complete.

Similar to the above.

Beginning :

अस्य श्रीहनुमन्मालामन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, हनुमान् देवता; ऐं बीजं, अञ्जनेति शक्तिः, मम हनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

मारय मारय शोषय शोषय ज्वलय ज्वलय प्रहारय प्रहारय महाबल उपस्पृशय हनुमते स्वाहा ॥

No. **7692.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 8. Lines, 7 on a page.

Begins on fol. 2*a* of the MS. described under No. 6157.

Complete.

It is taken from the Brahmōttarakhaṇḍa.

Similar to the above.

Beginning :

अमलकनकवर्णं प्रज्वलत्पावकाक्षं सरसिजनिभवक्त्रं सर्वदा सुप्रसन्नम् ।
पटुतरघनगात्रं कुण्डलालङ्कृताङ्गं रणजयकरवालं रामदूतं नमामि ॥

* * * *

ओं नमो भगवते श्रीरामदूताय हनुमते हुं फट् स्वाहा।

आग्नेयमण्डले मेषारूढहनूमते तोमरहस्तशक्तियुक्ताय।

End:

पद्मरागमणिकुण्डलप्रभापाटलीकृतकपोलभूषितम्।

दिव्यहेमकदलीवनान्तरे भावयामि पवमाननन्दनम्॥

Colophon:

इति ब्रह्मोत्तरखण्डे ब्रह्मनारदसंवादे हनुमत्कवचं (मालामन्त्रः) संपूर्णः॥

No. **7693.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Page, 1. Lines, 14 on a page.

Begins on fol. 81*b* of the MS. described under No. 5673.

Similar to the above,

Held to be efficacious in causing the accomplishment of one's desires.

Beginning:

अस्य श्रीहनुमन्मालामन्त्रस्य पुरन्दर ऋषिः, अनुष्टुप्छन्दः, श्रीवीरप्रतापहनुमान् देवता; यं बीजं, रं शक्तिः, लं कीलकं, मम इष्टकाम्यार्थसिद्ध्यर्थे श्रीवीरप्रतापहनुमत्प्रीत्यर्थे जपे विनियोगः।

End:

अमलकनकवर्णं प्रज्वलत्पावकाक्षं सरसिजनिभवक्त्रं सर्वदा सुप्रसन्नम्।

पटुतरघनगात्रं कुण्डलालङ्कृताङ्गं रणजयकरवालं रामदूतं नमामि॥

No. **7694.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 132*a* of the MS. described under No. 29.

Complete.

Similar to the above.

Beginning:

अस्य श्रीहनुमन्मालामन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, ह्रां बीजं, ह्रीं कीलकं, मम इष्टकाम्यार्थसिद्ध्यर्थे जपे विनियोगः ।

End:

सर्वारिष्टशमनाय सर्वशत्रुविनाशनाय सर्वविघ्नविनाशनाय ग्रहपीडानिवारणाय शृङ्खलबन्धविमोचनाय असाध्यसाधनाय ओं ह्रीं श्रीं फट् स्वाहा ॥

No. **7695.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 4. Lines, 6 on a page.

Begins on fol. 35*a* of the MS. described under No. 2424, wherein it has been apparently omitted to be given as a separate work in the list of other works.

Complete.

Similar to the above.

Held to be efficacious in removing various kinds of dreadful troubles and difficulties.

Beginning:

ओं नमो भगवते हनुमते प्रकटपराक्रमाय सर्वदिङ्मण्डलशोभित[ा]य शोधवलीकृतनेत्रा(जगत्रया)य वज्रदेहाय रौद्रावताराय ।

End:

सञ्जीवपर्वतोद्धार मनोदुःखनिवारण ।
घोरो(रानु)पद्रवान् सर्वान् नाशयाक्षासु(श)रान्तक ॥

Colophon:

हनुमत्कवचं(न्मालामन्त्रः)सम्पूर्णः ॥

No. **7696.** हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 4. Lines, 8 on page.

Begins on fol. 29*a* of the MS. described under No. 6005.

Complete.

Considered to have the power to enable one to drive off evil spirits.

Beginning:

ओं क्रां अविल अविल अनेकजन्मावतार अनन्तबडबानलकोटि-सूर्यकोटिप्रकाश वायुकुमार अञ्जनादेविसन्दर्शन पार्वतीदेविवरपुत्र देव सदाशिवमूर्ते परनारीसहोदर बालब्रह्मचारिन् गम्भीरशब्द ।

End:

सर्वक्रूरग्रहोच्चाटनाय उग्रराक्षसग्रहोच्चाटनाय वीररामावतारवीरहनुमदवतार श्रीवीरप्रताप जा जा ह ह ह हनुमते स्वाहा ॥

No. 7697. हनूमन्मालामन्त्रः.

HANŪMANMĀLĀMANTRAḤ.

Pages, 2. Lines, 21 on a page.

Begins on fol. 18*b* of the MS. described under No. 2373, wherein it has apparently been omitted to be shown as a separate work in the list of other works.

Complete.

The repetition of this Mantra, which is also addressed to Hanūmat, is considered to have the power to take away the poison from poisonous creatures, to calm down evil spirits and to enable one to accomplish one's desires

Beginning:

स्वस्ति समस्तलोकविस्तारक श्रीपार्वतीप्रियपुत्र अञ्जनादेवीवरगर्भसम्भूत रामलक्ष्मणानन्दकर ।

End:

जलचरबिलचरस्थलचररात्रिञ्चरदिवाचरसर्वक्रूरनिर्विषं कुरु कुरु सर्वदुष्टशमनाय असाध्यसाधनाय ओं फट् फट् स्वाहा ॥

No. 7698. हयग्रीवकवचः.

HAYAGRĪVAKAVACAḤ

Substance, palm-leaf. Size, 6¾ × 1½ inches. Pages, 6. Lines, 7 on a page. Character, Grantha. Condition, good. Appearance, old.

Begins on fol. 30*b*. The other works herein are Hayagrīvaikākṣaramantra 1*a* and 2*a*, Hayagrīvamantra 1*b*, Hayagrīvaikādaśākṣaramantra 1*b*, Hayagrīvānuṣṭubhamantra 2*b*, 5*a* and 27*a*, Hayagrīvapūjā 2*b* and 3*a*, Hayagrīvamantraprayōga 4*a*, Hayagrīvakalpa 6*a*, Hayagrīvapañjara 27*b*, Hayagrīvapañjarakalpa 33*a*, Hayagrīvāṣṭōttaraśata 39*b*, Hayagrīvamālāmantra 42*a*.

Complete.

This Kavaca-mantra is addressed to Hayagrīva; and its repetition is held to be efficacious in securing safety and protection and in bringing about the accomplishment of one's desires.

Beginning:

नारद उवाच—

ऋषिरस्य हयग्रीवो देवता च स एव हि ।
प्रोक्तमानुष्टुभं छन्दस्सर्वार्थे विनियुज्यते ॥
कलशाम्भोधिसङ्काशं कमलायतलोचनम् ।
कलानिधिकृतावासं कर्णिकापीठसंस्थितम् ॥

*　　*　　*　　*

हयग्रीवश्शिरः पातु ललाटं चन्द्रमध्यगः ।
शास्त्रात्मको दृशौ पातु पातु शब्दात्मकश्श्रुती ॥

End:

इतीदं कीर्तयेद्यस्तु कवचं देवपूजितम् ।
सर्वान् कामानवाप्नोति हयग्रीवप्रसादतः ॥

Colophon:

इति नारदसंहितायां हयग्रीवकवचस्समाप्तः ॥

No. **7699.** हयग्रीवपञ्जरम्.

HAYAGRĪVAPAÑJARAM.

Pages, 7. Lines, 7 on a page.

Begins on fol. 27*b* of the MS. described under No. 7698

Complete.

Similar to the above.

Beginning:

अस्य श्रीहयग्रीवपञ्जरमहामन्त्रस्य सङ्कर्षण ऋषिः, अनुष्टुप् छन्दः, श्रीहयग्रीवो देवता; ऋं बीजं, नमश्शक्तिः, क्रों कीलकं, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

End:

मन्दारकुन्दस्फटिकमहनीयोरुवर्चसे ।
मनीषाप्रददेवाय महाश्वशिरसे नमः ॥
इति द्वादशमन्त्रेण नमस्कुर्याज्जनार्दनम् ।
प्राह प्रसन्नवदनः पाराशर्यमानिन्दितम् ॥

No. **7700.** हयग्रीवमन्त्रः.

HAYAGRĪVAMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 1*b* of the MS. described under No. 7697.

Complete.

In this Mantra the supplicant prays to Hayagrīva for plenty of good food.

Beginning:

अथ दधिभक्तहयग्रीवमन्त्रः—

ब्रह्मा ऋषिः, अतिच्छन्दः, हयग्रीवो विष्णुर्देवता । अङ्गन्यासादिकं पूर्ववत् ।

End:

ओं नमो भगवते हयशिरसे अन्नाधिपतये अन्नदाय अक्रूरायाक्रूर-कर्मणे भगवन् भक्ष्यभोज्यान्नदानमावहावह स्वाहा । हयग्रीवमन्त्रानन्तरं ओं ह्रूं ह्रं सः

विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे ।
तुभ्यं नमो हयग्रीव विद्याराजाय विष्णवे ॥

स्वाहा सो ह्रं ह्रूं ओं । पूजादिकमनुष्टुब्वत् ॥

No. **7701.** हयग्रीवमन्त्रः.

HAYAGRĪVAMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 286*b* of the MS. described under No. 5477, wherein it is found in the Mantramālikā (Ākāśabhairavakalpa) 273*a*, in the list of other works.

Complete.

The repetition of this Mantra addressed to Hayagrīva is considered to be efficacious in effecting the accomplishment of one's desires.

Beginning:

अस्य श्रीहयग्रीवमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीहय-ग्रीवरूपी विष्णुर्देवता; ह्रं बीजं, सौः शक्तिः, मम इष्टकाम्यार्थसिद्ध्यर्थे जपे बिनियोगः ।

End:

मन्त्रः—

ह्रें हयशिरसे नमः ॥

हविद्यां निजपेन्मन्त्रमयुतं तत्प्रसिद्धये ।
नित्यमष्टोत्तरशतमष्टाविंशतिमेव वा ॥

Colophon:

इति हयग्रीवमन्त्रः ॥

No. 7702. हयग्रीवमन्त्रः.

HAYAGRĪVAMANTRAḤ.

Pages, 2. Lines, 28 on a page.

Begins on fol. 243*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* in the list of other works.

Incomplete.

Similar to the above.

Beginning:

अस्य श्रीहयग्रीवमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीहयग्रीवरूपी विष्णुर्देवता; हं बीजं, सौं शक्तिः, ममेष्टकाम्यार्थसिद्ध्यर्थे विनियोगः ।

End:

शङ्खचक्रधरं देवं वनमालाविभूषितम् ।
श्रीवत्सकौस्तुभधरं दिव्याभरणभूषितम् ॥
मू.

No. 7703. हयग्रीवमन्त्रः.

HAYAGRĪVAMANTRAḤ.

Pages, 2. Lines, 10 on a page.

Begins on fol. 94*a* of the MS. described under No. 5566, and not on fol. 98 as shown therein.

Incomplete.

Same as the above.

No 7704. हयग्रीवमालामन्त्रः.

HAYAGRĪVAMĀLĀMANTRAḤ.

Pages, 10. Lines, 7 on a page.

Begins on fol. 42*a* of the MS. described under No. 7698.

Complete.

The repetition of this Mantra addressed to Hayagrīva is considered to have the power to enable one to secure protection, to drive off and destroy and do several other kinds of harm to one's enemies, and to counteract the evil effects of hostile Mantras and Tantras, etc.

Beginning:

अस्य श्रीहयग्रीवमहामालामन्त्रराजस्य शरभ ऋषिः, अतिजगती छन्दः, परमात्मा श्रीहयग्रीवो देवता; ओं क्ष्रां बीजं, क्ष्रौं शक्तिः, स्रूं कीलकं, आत्मरक्षणोच्चाटनमारणमोहनस्तम्भनसर्वार्थसिद्ध्यर्थे जपे विनियोगः ।

End:

परमन्त्रान् छेदय छेदय भीं भीं भं भं कुक्कुटगृध्रमण्डूकव्याघ्रभल्लूकवराहादिप्रयोगनानाविधतन्त्रादीन् ह्रौं हन हन हुं फट् स्वाहा ॥

No. **7705.** हयग्रीवानुष्टुभमन्त्रः.

HAYAGRĪVĀNUṢṬUBHAMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 2*b* of the MS. described under No. 7698.

Complete.

The repetition of this Mantra, which is in the form of an Anuṣṭup stanza, is believed to have the power to bestow on one wisdom and learning.

Beginning:

अथ हयग्रीवप्रसङ्गाद्धयग्रीवानुष्टुप्मन्त्रो लिख्यते । ब्रह्मा वा सङ्कर्षणो वा ऋषिः, अनुष्टुप् छन्दः, हयग्रीवो देवता, ऋं बीजं, नमश्शक्तिः, ज्ञानार्थे ।

End:

ऋग्यजुस्सामरूपाय वेदाहरणकर्मणे ।
प्रणवोद्गीथवचसे महाश्वशिरसे नमः ॥

इति मन्त्रः । अयुतं जपेत् । विद्याप्रधानोऽयं मन्त्रः ॥

No. 7706. हयग्रीवानुष्टुभमन्त्रः.

HAYAGRĪVĀNUṢṬUBHAMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 35*a* of the MS. described under No. 3056.

Complete.

The Ānuṣṭup stanza given here differs only very slightly from that given under the previous number.

Beginning:

अस्य श्रीहयग्रीवानुष्टुप्महामन्त्रस्य संकर्षण ऋषिः, देवी गायत्री छन्दः, श्रीहयग्रीवो देवता; ह्रीं बीजं, उं शक्तिः, हयग्रीवप्रीत्यर्थे जपे विनियोगः।

End:

मन्त्रः—

ओं ऋग्यजुस्सामरूपाय वेदाहरणकर्मणे।
प्रणवोद्गीथयशसे महाश्वशिरसे नमः॥

No. 7707. हयग्रीवानुष्टुभमन्त्रः.

HAYAGRĪVĀNUṢṬUBHAMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 5*a* of the MS. described under No. 7698.

Complete.

Similar to the above; the Anuṣṭup stanza here given is different from the one found in the previous number.

Beginning:

हयग्रीवानुष्टुभमन्त्रान्तरं लिख्यते।

ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, हयग्रीवो देवता। तारपूर्वमन्त्रस्य पादैस्समस्तैर्व्यस्तैश्च पञ्चाङ्गानि।

End:

उद्गिरत्प्रणवोद्गीथ सर्ववागीश्वरेश्वर।
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय॥

इति मन्त्रः । द्वात्रिंशल्लक्षजपः ।

मधुसिक्तैः कुन्दपुष्पैर्दशांशं पुरश्चरणहोमः ।

* * * *

वचामनेन संजप्तां भक्षयेत्प्रातरन्वहम् ।

सर्ववेदागमादीनां व्याख्याता जायतेऽचिरात् ॥

No. **7708.** हयग्रीवानुष्टुभमन्त्रः.

HAYAGRĪVĀNUṢṬUBHAMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 27*a* of the MS. described under No. 7698.

Complete.

Similar to the above; the Anuṣṭup Mantra is not given herein.

Beginning :

अस्य श्रीहयग्रीवानुष्टुप्महामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः श्रीहयग्रीवः परमात्मा देवता ; ह्रां बीजं, ह्रीं शक्तिः, क्रों कीलकं, मम श्रीहयग्रीवप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End :

शङ्खाभः शङ्खचक्रे करसरसिजयोः पुस्तकं चान्यहस्ते

बिभ्राणो ज्ञानमुद्रां लसति परकरे मण्डलस्थः सुधांशोः ।

आसीनः पुण्डरीके तुरगवरशिराः पूरुषो मे पुराणः

श्रीमानज्ञानहारी मनसि निवसतामृग्यजुस्सामरूपः ॥

No. **7709.** हयग्रीवाष्टाक्षरमन्त्रः.

HAYAGRĪVĀṢṬĀKṢARAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 15*a* of the MS. described under No. 5786.

Complete.

The repetition of this Mantra consisting of eight syllables is believed to have the power to secure for one the favour of Hayagrīva. The syllable Oṁ, both in the beginning and in the end, is not to be taken as forming part of the Mantra proper.

Beginning:

गुरुनमस्कारः । ओं ह्रां हयग्रीवाय नमः ओं इति प्राणायामः १२. पूर्णज्ञानेत्यादिन्यासः ।

अस्य श्रीहयग्रीवाष्टाक्षरमहामन्त्रस्य ब्रह्मा ऋषिः, देवी गायत्रीं छन्दः, श्रीहयग्रीवो देवता, हयग्रीवप्रेरणया हयग्रीवप्रीत्यर्थे जपे विनियोगः ।

End:

ओं ह्रां हयग्रीवाय नमः ओं इति जपः ।

उपसंहारः पूर्ववत् ॥

No. **7710.** हयग्रीवैकाक्षरमन्त्रः.

HAYAGRĪVAIKĀKṢARAMANTRAH.

Page, 1. Lines, 7 on a page.

Begins on fol. 2*a* of the MS. described under No. 7698.

Complete.

Similar to the above; the Mantra consists only of one syllable.

Beginning:

शास्त्रान्तरोक्तपक्षविशेषेण हयग्रीवैकाक्षरं लिख्यते—

ब्रह्मा ऋषिः, गायत्री छन्दः, हयग्रीवो देवता; हं बीजं, सः शक्तिः, ह्रां ह्रीं इत्यादिनाङ्गानि ।

End:

हूं—इति मन्त्रः पक्षचतुष्करूपः ।

श्वेतपद्मैर्दशांशपुरश्चरणहोमः । विद्याकामेन. . . . . .

सौः इत्यनेन सम्पुटीकृत्य जप्तव्यः ॥

No. 7711. हयग्रीवैकाक्षरमन्त्रः.

HAYAGRĪVAIKĀKṢARAMANTRAḤ.

Pages, 2. Lines, 7 on a page.

Begins on fol. 1*a* of the MS. described under No. 7693.

Complete.

The Mantra here is the same as under the previous number, but the preliminary details are different. An eight-syllabled Hayagrivamantra is also given in the end.

Beginning:

हयग्रीवैकाक्षरमन्त्रो लिख्यते--

ब्रह्मा ऋषिः, त्रिष्टुप् छन्दः, हयग्रीवो देवता; हकारो बीजं, ऊकारश्शक्तिः, वागैश्वर्यसिद्ध्यर्थे जपे विनियोगः ।

End:

हकारस(ल)कारचतुर्दशषष्ठस्वरान्यतरयुक्तबिम्बात्मकह्लौं—इति मन्त्रः। अथवा ह्रूं—इति ॥

अथ मन्त्रान्तरम्—

ऋष्यादिकं पूर्ववत् . . . . ह्रूं हयशिरसे नमः—इति मन्त्रः । पूजादिकं वक्ष्यमाणवत् ॥

No. 7712. हयग्रीवैकाक्षरमन्त्रः.

HAYAGRĪVAIKĀKṢARAMANTRAḤ.

Page, 1. Lines, 5 on a page.

Begins on fol. 35*b* of the MS described under No. 3056.

Complete.

Similar to the above; the Mantra and the preliminary details are however different.

Beginning:

हयग्रीवैकाक्षरमहामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीहयग्रीवो देवता; हं बीजं, सौं शक्तिः, ओं कीलकं, श्रीहयग्रीवप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

धवलनलिननिष्ठं क्षीरगौरं कराग्रे जपवलयसरोजैर्मुद्रितं पुस्तकं वा ।
दधदमवल(तममल)मस्रं(स्रा) कल्पजालाभिरामं तुरगवदनविष्णुं नौमि विद्यामसि(हि)ष्णुम् ॥

मन्त्रः—
ओं ह्सौं ॥

No. 7713. हयग्रीवैकाक्षरमन्त्रः.

HAYAGRĪVAIKĀKṢARAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol 24*a* of the MS. described under No. 6090.

Complete.

Similar to the above.

Beginning:

एवंगुणविशेषणविशिष्टायां शुभतिथौ हयग्रीवैकाक्षरमन्त्रजपं करिष्ये । अस्य श्रीहयग्रीवैकाक्षरमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीहयग्रीवमहाविष्णुः परमात्मा देवता; ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, मम हयग्रीवप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

मनुः—ह्सौं

ऋग्यजुस्सामरूपाय वेदाहरणरूपिणे ।
प्रणवोद्गीथवचसे महाश्वशिरसे नमः ॥ ओं ह्रौं
उद्गीथप्रणवोद्गीथ सर्ववागीश्वरेश्वर ।
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय ॥ स्वाहा ।

No. 7714. हयग्रीवैकाक्षरमन्त्रः.

HAYAGRĪVAIKĀKṢARAMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 33*a* of the MS. described under No. 5858.

Complete.

Slightly different from the above.

Beginning:

एवंगुणविशेषण = तिथौ हयग्रीवैकाक्षरमन्त्रजपं करिष्ये ।

* * * *

गायत्रीप्राणायामत्रयं कृत्वा, वागीश्वराय विद्महे हय(ग्रीवाय)धीमहि । तन्नो हं स(:) प्रचोदयात् ।

The remaining portion is the same as in the previous number.

No. 7715. हयग्रीवैकादशाक्षरमन्त्रः.

HAYAGRĪVAIKĀDAŚĀKṢARAMANTRAḤ.

Page, 1. Lines, 7 on a page.

Begins on fol. 1*b* of the MS. described under No. 7698.

Complete.

The repetition of this Mantra consisting of 11 syllables is believed to have the power to endow one with learning.

Beginning and **End**:

अथैकादशाक्षरमन्त्रः—

ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, हयग्रीवो देवता; बीजेनाङ्गानि, पूर्ववद्ध्यानादि । ह्रीं हयशिरः ह्रीं क्रों हुं फट् नमः—इति मन्त्रः । विद्याफलप्रयोज(धा)नोऽयं मन्त्रः ॥

No. 7716. हरिद्रागणपतिमन्त्रः.

HARIDRĀGAṆAPATIMANTRAḤ.

Page, 1. Lines, 18 on a page.

Begins on fol. 290*b* of the MS. described under No. 5477, wherein it is found in the Mantramālikā (**Ākāśabhairavakalpa**) 273*a* in the list of other works.

Complete.

This Mantra is addressed to Haridrāgaṇapati, a manifestation of Vināyaka; and its repetition is considered to be efficacious in bringing about the accomplishment of one's desires.

Beginning:

अस्य श्रीहरिद्रागणपतिमन्त्रस्य मदन ऋषिः, अनुष्टुप् छन्दः, श्रीहरिद्रागणपतिर्देवता; ग्लौं बीजं, स्वाहा शक्तिः, ममेष्टकाम्यार्थे विनियोगः ।

End:

मन्त्रः—

ओं हूं हूं गं ग्लौं हरिद्रागणपति(ते) वरवरद सर्वजनहृदयं स्तम्भय स्तम्भय स्वाहा—इति ॥

No. 7717. हरिद्रागणपतिमन्त्रः.

HARIDRĀGAṆAPATIMANTRAḤ.

Pages, 2. Lines, 28 on a page.

Begins on fol. 246*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीहरिद्रागणपतिमन्त्रस्य मदन ऋषिः, अनुष्टुप् छन्दः, श्रीहरिद्रागणपतिर्देवता; ग्लौं बीजं, स्वाहा शक्तिः, ममेष्टकाम्यार्थ-सिद्ध्यर्थे विनियोगः ।

End:

ओं हुं गं ग्लौं हरिद्रागणपतये वरवरद सर्वजनहृदयं स्तम्भय स्तम्भय स्वाहा ॥

No. 7718. हरिद्रागणपतिमन्त्रः.

HARIDRĀGAṆAPATIMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 96*a* of the MS. described under No. 5566 and not on fol. 100 as shewn therein.

Complete.

Same as the above.

No. 7719. हवनमन्त्रः.
HAVANAMANTRAḤ.

Page, 1. Lines, 14 on a page.

Begins on fol. 80*b* of the MS. described under No. 5673.

Complete.

The repetition of this Mantra, which is addressed to the goddess Pratyaṅgirā, is to be followed by a ceremonial fire-offering and is considered to have the power to enable one to destroy evil spirits.

Beginning:

ओं यां कल्पयन्ति नोऽरयः क्रूरां कृत्यां वधूमिव । तां ब्रह्मणाप-निर्णुद्मः प्रत्यक्कर्तारमृच्छतों स्वाहा ।

End:

ओं मिलि मिलि ब्रह्म ब्रह्म ब्रह्म ब्रह्म य शुम्भिनि खे चर चर गुरु गुरु राज राज हंस हंस स्वाहा ॥

No. 7720. हसन्तीमन्त्रः.
HASANTĪMANTRAḤ.

Pages, 2. Lines, 5 on a page.

Begins on fol. 27*a* of the MS. described under No. 2848, wherein it is found in the Āmnāyamantramālikā 16*a*.

Complete.

This Mantra is addressed to Śyāmalā or the goddess Mātaṅgī conceived as possessing a smiling countenance; and its repetition is considered to have the power to remove fears, dangers and obstacles.

Beginning:

अस्य श्रीहसन्तीमन्त्रस्य मतङ्ग ऋषिः, पङ्क्तिश्छन्दः, हसन्त्यम्बा देवता, ऐं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, ह्रीमित्यादिन्यासः ।

End:

ओं ह्रीं हसन्ती(न्ति) हसन्ता(सिता)लापमातङ्गि परिचारिके भयविघ्ना-पदां नाशं कुरु कुरु ठ ठ ठ हुं फट् स्वाहा ॥

No. **7721.** हसन्तीमातङ्गीमन्त्रः.

HASANTĪMĀTAṄGĪMANTRAḤ.

Pages, 2. Lines, 14 on a page.

Begins on fol. 11*a* of the MS. described under No. 5673, wherein it is found in the Āmnāyamantramālikā 1*a*, in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीहसन्तीमातङ्गीमहामन्त्रस्य मतङ्गेश्वर ऋषिः, गायत्री छन्दः, श्रीहसन्ती मातङ्गीश्वरी देवता; ह्रीं बीजं, स्वाहा शक्तिः, मातङ्गीति कीलकं, [म]मत्सकलापन्निवारणार्थे जपे विनियोगः ।

End:

मनुः—

ओं ह्रीं हसन्ति हसितालापे मातङ्गि परिचारिके मम भयविघ्नापदां नाशं कुरु कुरु ठ ठ ठ हुं फट् स्वाहा श्रीहसन्तीश्री ॥

No. **7722.** हसन्तीश्यामलामन्त्रः.

HASANTĪŚYĀMALĀMANTRAḤ.

Pages, 2. Lines, 10 on a page.

Begins on fol. 228*b* of the MS. described under No. 124, wherein it is found in the Ṣaḍāmnāyamantra 228*b* in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीहसन्तीश्यामलामन्त्रस्य मतङ्गभगवानृषिः, अनुष्टुप् छन्दः, हसन्तीश्यामला देवता; हसन्तीश्यामलाप्रसा—गः ।

End:

ओं ह्रीं—

हसन्ति हसितालापे मातङ्गि परिचारिके भयविघ्नापदां नाशं कुरु कुरु ठ ठ ठ हुं हुं फट् स्वाहा । हसन्त्यम्बादिव्यश्रीपादुकां पूजयामि ॥

No. 7723. हसन्तीश्यामलामन्त्रः.
HASANTĪŚYĀMALĀMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 4*a* of the MS. described under No. 673, wherein it is found in the Ṣaḍāmnāya 1*a* in the list of other works.

Complete.

Similar to the above.

Beginning:

अस्य श्रीहसन्तीश्यामलाम्बामन्त्रस्य मतङ्ग ऋषिः, अनुष्टुप् छन्दः, हसन्त्यम्बा देवता ; क्लीं बीजं, ह्रीं शक्तिः, सौः कीलकं, मम हसन्त्यम्बाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

End:

ऐं ह्रीं श्रीं हसन्ति हसितालापे मातङ्गि परिचारिके भयविघ्नापदां नाशं कुरु कुरु स्वाहा ।

हसन्त्यम्बाश्रीपा . . . नमः ॥

No. 7724. हिरण्यगर्भसूक्तमन्त्रः.
HIRAṆYAGARBHASŪKTAMANTRAḤ.

Pages, 3. Lines, 8 on a page.

Begins on fol. 21*a* of the MS. described under No. 5786.

Complete.

This Mantra is addressed to Hiraṇyagarbha. It consists of ten Ṛks in the 121st and five Ṛks in the 122nd Sūkta of the tenth Maṇḍala of the Ṛgvēda.

Beginning:

गुरुनमस्कारः। ओं हिरण्यगर्भाय नमः—इति प्राणायामः १२.

* * * *

अस्य श्रीहिरण्यगर्भसूक्तमहामन्त्रस्य भृगुः ऋषिः, त्रिष्टुप् छन्दः, हिरण्यगर्भो देवता, हिरण्यगर्भप्रेरणया हिरण्यगर्भप्रीत्यर्थे पञ्चदशर्चहिरण्यगर्भसूक्तमहामन्त्रजपे विनियोगः ।

End:

त्वं दूतः प्रथमो वरेण्यस्स हूयमानो अमृताय मत्स्व ।
त्वां मर्जयन्मरुतो दाशुषो गृहे त्वां स्तोमेभिर्भृगवो विरुरुचुः—
इत्यन्तं जपः । उपसंहारः पूर्ववत् ॥

No 7725. हिरण्यगर्भाष्टाक्षरमन्त्रः.

HIRAṆYAGARBHĀṢṬĀKṢARAMANTRAḤ.

Page, 1. Lines, 8 on a page.

Begins on fol. 22*b* of the MS. described under No. 5786.

Complete.

The repetition of this eight-syllabled Mantra is intended to propitiate Hiraṇyagarbha.

Beginning:

गुरुनमस्कारः ।
ओं हिरण्यगर्भाय नमः ओं इतिप्राणायामः १२.

* * * *

अस्य श्रीहिरण्यगर्भाष्टाक्षरमहामहामन्त्रस्य हिरण्यगर्भ ऋषिः, गायत्री छन्दः, हिरण्यगर्भो देवता, हिरण्यगर्भप्रेरणया हिरण्यगर्भप्रीत्यर्थे हिरण्यगर्भाष्टाक्षरमहामन्त्रजपे विनियोगः ।

End:

ओं हिरण्यगर्भाय नमः ओं इति जपः । उपसंहारः पूर्ववत् ॥

No. 7726. हिरण्यदेवीसूक्तमन्त्रः.

HIRAṆYADEVĪSŪKTAMANTRAḤ.

Pages, 3. Lines, 9 on a page.

Begins on fol. 4*a* of the MS. described under No. 21.

Complete.

The repetition of this Mantra consisting of Vedic Ṛks is intended to propitiate the goddess Mahālakṣmī.

The Vedic Ṛks here given go by the name of Śrīsūkta, for which see under Nos. 17 to 22 *ante*.

Beginning:

अस्य श्रीहिरण्यदेवीसूक्तमहामन्त्रस्य श्री आनन्दकर्दम ऋषिः, श्रीचिक्लीत ऋषिः, श्रीमाता ऋषिः, आद्यास्तिस्रोऽनुष्टुप् छन्दः, चतुर्थी बृहती छन्दः, पञ्चमषष्ठौ त्रिष्टुप् छन्दः, सप्तम्यष्टम्यावनुष्टुप् छन्दः, शेषाः प्रस्तारया पङ्क्तिश्छन्दः, हिरण्या देवता, मम श्रीहिरण्यमहालक्ष्मीप्रसादसिद्ध्यर्थे विनियोगः ।

End:

श्रीं क्लीं श्रीं तां म आ वह श्रीं जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ।
यश्शुचिः प्रयतो भूत्वा जुंह्व(जुहुया)दाज्यमन्व(हम्) ।
श्रियः पञ्चदशर्चञ्च श्रीकामः सततञ्जपेत् ॥

* * * *

सक्तुमिव तितउना पुनन्तो मनसो वाचमक्रत ।
यत्रा सखायस्सख्यानुजानते भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥

No. **7727.** हुतभूषणीमन्त्रः.

HUTABHŪṢAṆĪMANTRAḤ.

Pages, 2. Lines, 28 on a page.

Begins on fol. 253*a* of the MS. described under No. 581, wherein it is found in the Mantramālikā 229*a* in the list of other works.

Complete.

This Mantra is addressed to the goddess Hutabhūṣaṇī, a manifestation of Śakti; and its repetition is considered to have the power to enable one to render the eye sight and minds of disliked people useless so that they may not know or understand what is going on.

Beginning:

ओं नमो भगवति हुतभूषाणि मम विरयुगलनसमस्याज्ञाव्याप्रसादित स्वाहा ।

End:

सर्वजनमुखचक्षुर्मनस्तिरस्करणं कुरु कुरु स्वाहा ॥

No. 7728. हुतभूषणीमन्त्रः.

HUTABHŪṢAṆĪMANTRAḤ.

Page, 1. Lines, 10 on a page.

Begins on fol. 100*b* of the MS. described under No. 5566, wherein it has been omitted to be given in the list of other works

Complete.

Same as the above.

No. 7729. हृल्लेखामातृकासरस्वतीमन्त्रः.

HṚLLĒKHĀMĀTṚKĀSARASVATĪMANTRAḤ.

Pages, 2. Lines, 6 on a page.

Begins on fol. 39*a* of the MS. described under No. 7274.

Complete.

On the ceremonial touching of certain parts of the body while repeating at the same time the Mantra-formulas obtained by putting the successive letters of the alphabet and the word नमः after ऐं ह्रीं श्रीं ह्रां. This Nyāsa is considered to be a preliminary ceremonial to the repetition of the Śrīvidyāmantra

Beginning:

अस्य श्रीहृल्लेखामातृकासरस्वतीमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, हृल्लेखामातृका सरस्वती देवता; हं बीजं, रं शक्तिः, ईं कीलकं, ममोपास्यमानश्रीविद्याङ्गत्वेन हृल्लेखामातृकान्यासे विनियोगः ।

End:

ऐं ह्रीं श्रीं ह्रां अं नमः इति क्षं नमःपर्यन्तम् ॥

INDEX.

[NOTE.—The names printed in *italics* are those of the works described.]

Central Archaeological Library,
NEW DELHI. 23610.

Call No. 091.4912/G.O.M.L.M

Author—Rangacharya, M.

Title—A Descriptive Catalogue of the Sans. Manuscripts ...

Date of Return

"A book that is shut is but a block"

CENTRAL ARCHAEOLOGICAL LIBRARY
GOVT. OF INDIA
Department of Archaeology
NEW DELHI.

Please help us to keep the book clean and moving.